DPN 6795

Title :[आयुर्वेदचिकित्साग्रन्थ] /[ĀYURVEDACIKITSĀGRANTHA]

Run. No. 7520

Cat. No. 20

Micro. No.

Subject Āyurveda

Religion : Hindu / Bauddha

Language : Skt. / New. / Nep. / Skt.- New. / Maith.- New. / New.- Nep. /

Size in cms. 29 × 13·5

Folios 78
missing 1-12

Lines (in a page) 11

Compl. / Incompl.

Chapt. / act /

Author / translator

Scribe / donor बाबानानी वैद्य

Date: NS / SS / VS / KS

Ruler / place

Script : New. / Dev. / Bhuj. / Ran. /

Illus. :

Material : palmleaf / paper / thyasaphu / one side yellow

Condition : fine / damaged by worms, rats, water /

Beginning, colophon, post-colophon :

Fol. 30a: अथ रास्न्यादि घृतं ॥ मीम वटकमंडूर [Fol. 41a]

Fol. 85a: इति कर्णरोगाधिकित्सा ॥ Fol. 86b: त्रिफलादि घृतं

नासनं॥ भनष्टिलाद्यंतलीं॥ ॥कुंकुमकूष्टरकिमिनाशिरकिमियुद्वेदिभज्ञारकं॥ गुडलवघट्ट
गलगंडभियानं॥ ॥विरुदंबुलविल्वमूलकाभ्यांयुतायांघृता।जामरुषीजिसदनगुडकंपूवि
गंगैभाजा॥ ॥गुडूविल्वत्रसंवाद्यद्वरुजिद्वासाथवा॥ क्षीरयूकांगुतांयिलासर्वकामलरुजकं
॥ ॥गुरुलाकटूकरुगानथयतिविषास्मा॥ जनीद्वयसंयुकंसमरुगंपूवल्लायतायावं
द्यतानिसर्पानिभमद्यघृद्धिंउनत्तमं॥ सद्वाद्वयघृतालरुंरुव्याकामलयाघृधं॥ ॥नयाकम्वरुगं
द्रायांयुतनासरुयाजिगंरुदनानाश्वगंनकामलावातनासनं॥ ॥कदूकाजाहिघामूर्छाहरिद्यावं
लसकारुलं॥यठलंवद्यनंमूर्छाणयमानायुजालरा॥सर्पियलीयर्षठवंरुनिम्वदवजायुवा॥पिप्प
लूमाक्षिकेसार्यिरयुक्तंकाजारकंयवतावकंपिरुजंयादंद्वंवयुष्मरुगनर्जा॥मूर्भंस्यरुग्दंवा
पिरुव्याविस्फटकंतथा॥कदूवाद्यघृतं॥ ॥रुग्विजणिरुलानिम्वबलामधूवासाघितंसद्वागमा
रुवंसार्यिठकामलारुगमूर्छा॥रुग्विद्राद्यघृतं॥ ॥कामलाहीरुजयामुलिलापिप्पलीनरुंमलं॥

कटुवद्वयुदरास्यश्लेष्मद्वेषकामलारुजत्॥ ॥द्वंगावकटुलासक्वाथिरुपूकृमान्वितान्पाघृता
जातिरिंद्रयवेवेषठयायठक्षीद्रुतीक्ष्णियं॥ ॥रुलाभद्रुचूर्णकांकनदुग्धिवन्नजं॥सप्तलाज
मिर्दंडंद्रव्यघृतागन्धमूत्रयं॥ ॥कदूतिक्तंलारुवृद्धंरुलाविल्वंथापियलामूलसयूकान्
क्षद्यसहितंपिवत्॥तक्रान्वानंतदुकंपाघृतागन्धमूत्रयं॥ ॥पिवत्खदिरतीयनंसघलारुज
ज्ञातिचामलाकाक्वलायवष्टिरुलाजगनीयूतं॥लाहुलिक्कासमध्यंरुलामकयसाद्रय॥ ॥
यूनन्नवालवृद्धाषविडंगपाचूचित्रकाकंरुंरुद्रिरुलादंतीचव्यकलिंगकं॥कदूकाधियली
मूलामूलंचतियलान्मिलंमंथूजलंतिगुडीवृद्धंलामूत्रायैवारकंयवत्॥कुठवंगुडकाकलातक्र
घलातिलंपिवत्॥तनपांडुगरश्वाहानलंम्निविषमज्वरान्॥क्षयथूरुघाषंरुंद्रिकुंकु
मिंतथा॥यूनन्नवायुरु॥ ॥वासागुडूचित्रिरुलाकद्वारुनिम्वनिम्बजाकाथःक्षौद्रयुताहरिद्रा
पाघृधिरुलासकामलारुं॥यामादिरु॥ ॥यूषघृतंरुलामूलंविडंगंचित्रकंसमं॥लाहुवृद्धेनव

गुडंकलाचूर्णं विवनगंश॥ मांसनवघृतंवा॥लिह्यात्क्षौद्रसर्पिषा॥सजयत्याशुरुग्दोषंक्षय
जंभयरुग्नन्यजात्॥॥किममांसिरुओजमन्द्राग्निबलमांसवर्द्धनं॥यत्किंचास्वस्थमात्यंवरुओजानल
रुग्बलं॥इन्द्रियाणांविशुद्धिश्चस्वप्नवर्द्धनमायुर्नं॥मांसनलरुग्नरुग्नजातंघृतंनवायसं॥न
वायसघृतं॥॥॥अथघृतंरुलायामूरुसिजानालीनीरुलाक्षाकाम्न्यवामूर्कमांसिक्षावदूरा॥
हिंगा॥जातावत्रीसिंहवाजानिविडंकंगरुपियलाभलिपंछंघीवृरुतीकं०कांजिकाभाय
नावरुल्लादविमलायदूगारुग॥अणमधूरसागासाखिंतंवयसांसकं॥यावत्यंतानिचूर्णानि लो
रुचूर्णानिदयुद्यावत्यंकंसमंक्षीरवांमूत्रघणंचयत्॥तांक्षमाणांगुटिकांवायवंघुलाम्बू
नाघृतागमनंजयत्यायुर्वलंतनूवासुजानाकिमिकुष्ठप्रमरुलीग्रहणीदोषलोपनुत्॥
रुगन्दौक्षसकासाश्वीरुगुल्मायजायरुग॥अथघृतंरुलोर्द्ध॥॥विवर्द्धयत्यंरुकिनंयलोथो॥
तयतिभात्रंजरयतिनरं॥॥यन्मूरुमार्गेगुदिजंयुयातिविलवलात्क्षैमधमघृतंरुग्दोषंयहि

तंभावंजसनासुद्धं वलवर्णाग्निवर्द्धनं॥पित्तघ्नमरुचिंकर्त्तृंभद्रागवनियाजयत्॥सुवर्द्धते
त्रिकंजंमाषंघृतंम्यावन्यनाम्यलं॥यानतघृलायनसंक्षयंयदंजयत्॥॥अनलायाश्सिरुन्या॥
वारुन्यनंनागकेशंजंअरुष्यंजनिजाधोयपिबेत्क्षीरयुतनया॥॥नलायत्रत्रयाभीजवासा
कषायंजांक्षकांसिताम्बुकरवंगंमृद्वीकाजयलान्मिता॥सचूर्णंमधुसंयुक्तंगुटिकांकाजयेद्दिवक
ॐनुदकमात्रातत्पेयंकारुदयन्नादिनादिन॥कासश्वासंक्षजंरुक्षंक्षयंक्षिप्तंरक्तंमदात्मा॥जकानि
क्षीवनंरुग्णवार्द्धभूलमंजावकं॥लाबशीरुद्यवाताभ्यंयत्तरुदकतकर्यं॥गुटिकांतयद्यावृक्षा
जकापिरुक्षनाशयत्॥नलादिनाशकं०॥॥कर्पूरजाकाश्मलासधूनाम्रहलरुयत॥ज्ञा
रुक्षानिरुंस्यान्मुरुक्काश्मगलंग्रहान॥सुखंकर्पूरजादि॥॥कर्पूरजचन्दनांजमृनींनंत्वे
तचन्दनं॥भागावलिवाजेकंक्षुनीलाल्यलसर्षकंजा॥भीतायनसंपेक्षायीनाद्वारुज्ञातायः
रुं॥कानिरुक्षयंपुनादी॥॥भागवयांमुमूलानांजसयरुद्वयंमतंतन्मंचरुवत्क्षीजंघृतंत्र

स्कोविषाचयत्॥जीवकर्षभकौमेदामहामेदाद्वयंवज्रा।काकोलीक्षीरकाकाकोलीमृद्वीकामधूका
तथामुद्गैर्यवैर्माषपर्णीविदार्याजकर्षभनीलनकुलसामधूर्सयुक्तंसिद्धंविश्रावयेद्धृषकाजकर्षि
भ्यांविषाणाभ्यांवाजकर्षभयवाभ्यांशुक्लशुक्लमल्लेवाजीकरणमुत्तमं॥मुद्गपर्णीजीवकर्षभ
रुसमूलंवयास्थासमूलकर्कटशृंग्योर्हरितं॥नवनीतमधुभ्यांलिह्यात्॥नवनीतसर्पिर्भ्यांविदारीबलाबला
नागबलासहस्रपुष्पीमाषविदार्यश्वगंधाभिर्वृष्यं॥बलाविदारीक्षीरकाकोलीक्षीरकाकोलीमधुकक्षी
रिकाभिर्वा॥शतावरीसाधितंविदारीबलाबलाभिर्वृष्यं॥बलाशतावरीविदारीजीवकर्षभकाकोली
क्षीरकाकोलीमधुकक्षीरिकाभिर्वा॥शतावरीकल्कंक्षीरेणसर्पिषःपचेत्॥तत्पयसाविदारीबलाबला
नागबलाभिर्वा॥ततःसमशर्कराक्षौद्रंलिह्यात्॥ततोवाजीवसेत्॥ ॥यवानीशालिंजीकं
नागरंवासमुपयुनक्ति॥ ॥बालासुवर्चलामरिचंनागरंपिप्पलीगुडाभयाश्चैकैकोत्तरंशतपलाबलाव
र्धमानिकाद्यापिप्पलीपर्यन्तंयुक्तवातुदरशोषगुल्मकासश्वासकासार्शोविरुजंतद्वृद्धिदायनंयजं॥बला
सुवर्चलाक्षीरकाकोलीक्षीरकाकोलीमधुकानीलामलं॥कल्कयेत्क्षीरकाकोलीवद्
घृतंपक्त्वासिद्धंलालायुक्तिकाक्षीरेसंयोज्यविदार्यादिगणोक्तैर्मधुरैश्चसाधयेद्यावत्क्षीरंघृतमात्रं
लावनाम॥शतावरीसुवर्चलाक्षीरकाकोलीक्षीरकाकोलीमधुकैर्घृतंपक्त्वासिद्धंलालायुक्तिकाक्षी
रेणसंयोज्यविदार्यादिगणोक्तैर्मधुरैश्चसाधयेद्यावत्क्षीरंघृतमात्रं॥ ॥कल्पाद्वाक्षीरेणलवणयवक्षारेणलवानाम

पृश्निपर्ण्यौ तावत्यौ गंधाकृष्णा सारिवा द्वे गवाक्ष्यौ विडंगानि वृद्धदारु विल्वं निर्गुंडी
लांगली क्षयजागलं नष्टशुक्रक्षय॥ क्षीरक्षय॥ ॥शृंगाटकैर्नाग्रगंधानागबलापुष्करास्थिनी
वृक्षादनी क्षीरशुक्लाः समनालिकाः क्षीरसर्पिषा पचेत्॥ शृंगाटकं वृद्धि॥ ॥बलापञ्चत्वचीरि
णीपिप्पल्यश्चैव जैवंतं यष्टिमधुकं खर्जूरं मृद्वीकाश्चेति बलामधुकखर्जूरमृद्वीकाक्षयबलान्मता॥ संवृद्धमधुनायुक्तं घृतिका
क्षयकल्पयेत्। क्षुद्रमाषातत्तुल्यैकाक्षयनादिनादिना॥ वातरक्तसक्तजिह्वाक्षुद्धिमूर्छामदं
दरुः॥ बलादि॥ ॥बलागन्धाश्वगंधावृक्षपूतीपुनर्नवायष्टिमधुकाक्षयंपिबेत्क्षीर

यांगक्षीरजायवत्यामधुमांसरसैरक्षामधुघृतंक्षीरानुपानंबालिकातक्षीरक्षतक्षयं॥ ॥समूलः
रुलयष्टायानिर्गुंडीखरशुक्रघृतंसिद्धंपीत्वाक्षयक्षीरघृतनिर्गुंडीघृतं॥ ॥
अथ मूलरुलयष्टायानिर्गुंडीखरशुक्रघृतंसिद्धंपीत्वाक्षय)॥ ॥याश्वगंधाजीवन्तीवृक्षपूतीशुक्लाविश्व
रुक्षाक्षिपत्रकैरंडसर्पिषश्चैतैःसघृतैःपिष्टैःकाम्पिल्लकं॥ ॥खरशुक्रंगवाक्षस्यमाक्षिकंनस
मंशितंपाययेद्धामकासघ्नंपुरीषंभायकरालकं॥ ॥मूंगमलामांसयवदाडिमाखोरक्षैक्षुनामू

लवार्षुणिकानागुडूचीकषायंवकलंरुक्षकंनसूषानवांगकरंजागरुंता॥नवांगसूष॥ ॥करुलं
कल्हारंशृंगीसुरोधान्यवचावरुयाशृंगीपर्ण्यौ टंकणं॥ क्षुद्राक्षारुलक्षणं। मधुहिंगुयुतायवं,
कालवातकरुन्निवेत्॥ कंठोगेमूत्रशुक्लाश्मसरुक्काङ्गभङ्गे॥ करुलादि॥ ॥वासुकस्वरस
यामधुयुक्तांहिंगुसैंधवं॥ पिरुलोमकरुकालोत्थैकाविडवेलवत॥ ॥विडंगसैंधवंकुष्ठं
व्याघहिंगुमनःशिलागंधकासर्षपैर्वारुभार्यांक्षीरयुक्तंकुलत्थवत्॥तस्यमानस्यकासघ्न
सान्नतस्यगंडूषेक्षवक्त्रेगन्धनालेवधूमपानंत्रयोऽजयत्॥मनःशिलालिकदलंवदर्योत्पलंबि
ल्वंसक्षौद्रंधूमपानंकुमहाकासनिवारणं॥धूमपानं॥ ॥कल्पत्रंमाक्षिकंगव्यसैंधवक्षौद्रसंयुतं॥ क्षा
द्रकनस्यंयुक्तंमयत्राक्षरुक्षंतं॥यथाक्षतज्वरयुक्तस्यकार्शऽयंकिनामया॥ ॥यथाशुंठीसमूक्षा
नाभिनासांयोगेनालवंगुडवैश्चैर्गुडंदद्याद्वैद्यश्चैवंकासहरंभवेत्॥ ॥हरितकिकाशुंठिमात्रै
र्युक्तंसर्पिःसमंपिबेत्॥कासश्वासाग्निदंबलदीपनं॥ ॥कर्षःकषोरुक्षंबलंबलक्षयेत्यस्योक्त्य
क्षैकर्षश्चामजिवस्यपिबेलीनांदातिमध्यगुडयावच्चूकानां॥सद्योवर्धनसाक्षयकासःसर्वेषेद्यर्वि

25 20 15 10 5 0 CMS 5 10 15 20 25 30 35 40

मूर्का ज्ञात्वा पिबेत्पश्चाद्वैद्यस्तांतत्र वादिदमौषधं वर्त्ता ॥ मंजिष्ठादिवृद्धं ॥ ॥ त्रिकटुत्रिफलामायूकंतालमंडु ॥
गुडूरवाकापिप्पलीमूलसंयुक्तंगुग्गुलुकीजीरसमन्वितं ॥ पूर्वेह्नेयंभातवघ्राकंकासंहंतानसंशय ॥
॥ ॥ देवदारुवलागास्नात्रिफलाद्यावघ्राकंविडंगमिनिशिताकुल्यंतद्वृद्धंपेरकासजिता ॥ यादुरुद्व
लहरु ॥ ॥ नागरंपिप्पलीपाभलगीचमाक्षिकंवानिवालहायंमधूनाकासश्वासंक्षयंक्षिप्रंनिधुनं ॥ वाला
नां ॥ पिप्पलीत्रिफलाचूर्णंमधुघृतसमायुतं ॥ वसलेह्यवायकंयंश्वासकासहरंपरं ॥ ॥ हरीतक
कंकष्टंगवाक्षीशुंठीरुग्गरुयाद्विगुणंपृथक्चूर्णंतुलायंसर्वकासघ्नाद्विक्षा
क्षसविनाशनं ॥ ॥ करहाटंगवाक्षंपिप्पलीमजिष्ठाशिग्रुपत्रमूलैरलाभधुकंवावा
सकयवाक्षमूलवघ्राटंगीकंकटकंयवानकंचूर्णंवंशाकंक्वाथंवामधुमूर्छितं ॥ वानप्रस्थगरुदवतम
कमरुलीमरुलीमकासिन्नियात्तानिलकरुकासश्वासक्षयान् ॥ • ॥ वृंगीसकंटकारटुगल्वर्चवंशका
त्रादृत्यर्मंर्ष्टमंजिष्ठावाशिग्रुगी ॥ नागरंनिंबपत्रंगमूलशुंठीरास्नावलाद्वंकंचवकंधासमहत्पंच
चूर्णंक्षौद्रंविषावाद्यंगुडंगुडिकांप्रकुर्यात्कासंतथाश्वासंयथूयानरुचंप्लीहंतथाविंशत्यामातृकंहरेद्यहि

श्री गणेशाय नमः

धारुणावेवचूर्णंवाक्षिकंनवृयिंगुग्गुलिकांजा ॥ मधूमादक ॥ ॥ सुगंधशुलक्षत्रवारुमालानवाघट्ट
यंवावलरुणसकासि ॥ शुष्कनाविनादीवातिदुर्बलरुग्वकीधमांसाग्निर्जसंयुत ॥ तस्यदोलंगरह
शदुग्धिकेलासीधिकाक्षितेक्षारःक्षयंजंवदानिशा ॥ ॥ वटादिगारुकुक्षाम्रकंचूपल्लवमाक्षिकैर्घासं
नाशमेद्यौगुडिकावृणास्यनरुद्धिकृत ॥ ॥ हिक्काश्वासानुपूर्वेतेलाक्षाखदूरुयाउजाधः
स्मधनंशकेवृद्धलोमनंमतं ॥ ॥ कोलमज्जेक्षुनंलाजाधिक्काकावरुनगोक्षिकंकृष्णाधना
शिलाशुंठीकासासंदधिनाशय ॥ याठल्यासरुलंचूर्णंकृत्वाबरुसमंक्वाथतेनादिकालेह
हिक्काश्वामधुसंयुता ॥ ॥ मधुकंमधुकंयकंपिप्पलीलाजकंगान्वितं ॥ नागरंगुडसंयुक्तंहिक्काघ्नं
नावनत्रयं ॥ ॥ वत्सलाचूर्णमंजिष्ठाजीवनीपुष्करंजातुवकासुरुकृष्णादशूलसासयमाक्षिकै
चूर्णंमत्स्यवातवंशकंजातरुयुक्तंकृतं ॥ हिक्काश्वासहरुंकासंजरुन्याश्चमूलनुत ॥ ॥ दुला
लरुकघ्राक्षंगीयथाधिचूर्णितं ॥ सर्पिषावाचयूषालरुंश्वासंकासंयतंकृतं ॥ गृरु
धूमयवक्षारपिप्पलिमंजिष्ठानिवश्वासकयत्रमालरुवल्लीवंतजंवाप्यव ॥ वधामूलकषा

यनयूक्तंघवचूर्णितं।कासश्वासज्वरसन्निपातंवाधबद्धकफलनाशनं॥ ॥क्षारकाहिंगुश्रृंगीशुंठीमाठु
वृक्षजसागनंसवतिमाश्वासकासहिक्काहृद्रोगिनाशनं॥ ॥त्रिकागधनुव्याघ्र्यर्कवंगकर्षेनव
धौतंधान्यजयवाक्षमूलरुग्श्वासजागविनाशनं॥ ॥उपदंशयोग॥ ॥हरीतकीनागज
मुक्तसंयुताघृतनवकुलगुंजिकामूर्खकिंशुकक्षारसंयदावाधतेऽहिकांनिर्व्रणयन्नाविनाविक
लाः॥ ॥मयूरशिख्यासार्द्धंमधुनापिप्पलीहृन्नागिनीयुतापथ्याजीवश्वासहिक्कांजयत्सदा॥ ॥
विहीतकानांचूर्णंकुर्यान्मात्रिकंसंयोज्यलेहयेत्कोलाम्लेनयश्वासनाशंसंभयथा ॥पंचलो
लीसवणस्यतत्क्ल्याग्रजपिप्पलीपिप्पलीद्वयलंवात्रिशृंगवलयलत्रयं।द्विपलंपिप्पलीमूलंचत्वा
रोमत्रिवस्यवापंचत्वाचाक्षकर्षकंपलार्द्धकंगतस्यवाशुक्लायाश्चत्वकर्षंसर्वंचुल्यंकृत्वाक्षेत्रा॥ न
वचूर्णंतंत्रंहरेत्सुन्मादग्रहनाशनं॥करंजिकानिलरुजैश्वासकासकासयहृद्रोगिकंकामिमूलप
त्रंविषमुलादजायहरुाक्षतालिसादि॥ ॥त्रिकटुकहरीतंवेतमधूकलसमन्वितं॥खजयदायद
हुंदवद्धवेधनयुजितं॥ ॥हरीतकीमुष्टिकत्वयंक्षौमधूसमायुतामधुसर्पियुतंलेह्यंहरेद्रु

जंघजं॥ ॥वृक्षाम्लवेतसंयद्वासेंधवत्रिनागजंपिप्पलीक्षौद्रसंयुक्तंघृताकागुंठिकावदनस्यगरुदरु
ग्रंक्षयलक्षंचयक्षराजनं॥ ॥यष्ट्याह्वित्रिफलाद्राक्षानीलोत्पलसमंक्षौद्रंकंतावाक्षयेत्वन्नातिवृ
नरवादन्नंनयेद्धादेलरुग्तंधरवध्यं॥ ॥हिंगजाजीमजवल्लीवासकदलकासमर्दरसैधान्पिप्पलीक्षौ
द्रसंयुक्तंरुधिरकासंजयत्मधुना॥हिंगजाज्यघृतं॥ ॥यक्षापिप्पलीयुक्तंत्र्यूषणंनागंगजवादीपत्रकं
कल्कंत्यागजनवादीपत्रंकंकल्कंघृतंहरुसमंक्षौद्रंसंयोज्यंखजायथाग्निबलरुमंतंप्रयोजयेत्॥ ॥कंटु
सीवेल्लंजाजीशुंठीकंजामिलवेतं॥धान्यालायक्षकाशालंपिप्पल्यश्चवन्दनात्यंलाधृतंजीवंतायक्षाग्रहंत
यंत्राग्रंक्षाद्रंदारुमानंयोसंधाजाजीनकंजागुडंग्रासमात्रंलमाक्षकल्कंबलात्रंकबलग्रहंवचुनाश्नं
वकानरुन्मूद्धोतायकंग्रहंक्षयेत्॥ ॥चन्दनाम्लालालासजीवंत्यंलवन्दनं॥रागवृक्षंकल्पंचयंका
लग्रंथिकंनागरंबल्वलंलाक्षंजंबेवंयाम्यवरंवरंसिंहीं वृद्धंक्षतंसमंग्रहंजलादयावरुंगुल्मंश्वासं
वकंक्षयंवृद्धमात्र्यंयाजयत्॥दीपनंविरुग्मनंवल्यंपुष्टिकरंगुरुं॥धातुवृद्धिकरंवल्यंक्रतुजंक्षय
बाधनं॥द्वितीयवन्दनाद्य॥ ॥त्रिजातकंपिप्पलिकंकेसरंनागलासपत्रंधूर्मेयुक्तंघृतंकाकोलीक्षत्रगुप्त

जम्बीरनखाग्निमान्द्यकृतिसाजिकायु॥ • ॥लवंगमलातवपिप्पलीकंकोलगंधकुर्यादिरुक्षमानश्च
लांत्र्यंकर्मजिवस्यदशापलानिवक्षात्रिमरुषधस्यासिताससंचूर्णमिदंत्रयंगानिमासप्रवलानिरुक्ष
॥कामरूपानावकयाघृतभल्लातकीनागरुद्धीसमूलं॥ रुक्ष०नासाक्षतंनंदनगंधकजाति
कर्षातिदीप्तिंचकुर्याद्विधिवच्चूर्णलवंगघृतमिदंनाशयेच्चमसूंदवगंधस्यादत्त॥षडंगलवंग
घृ॥ ॥तालीसषडंचयानागलवंगमुस्तांशकीद्वेतिरुक्षकुर्याच्चकोलनिलीकंकुरुकुरु॥ श्री १२
त्रयोदशयुतंबिल्वेलावदासवासघनेधान्याद्भागायुक्तमेलाघातिमयादनषविहितंलवंगं
सतार्द्धयुतं॥कर्षुसादजरुचिकोजठरमनेकायाग्निसंदीपनं॥गुल्मानविषुचिकागुदगुदज्वरम
सोद्रमीक्षदिहाकामान्यतिसारमुरुभयुतायलवंगकीर्तितंचूर्णंचरिषजामातिवदयितंरुचा
तासलाजनवजातवचूर्णं॥ ॥रुजनाप्रसवायथाक्षंक्षकंकघृतिलाधनंत्रिसंदीपनं
क्षयलवक्षाद्धकरुक्षितं॥ ॥इक्षुलयोतनयुतंवचनाषिक्षलक्षरुषवक्षलंसकरुक्षसकोप्य
क्षात्मकंवकयुतंवक्षारुक्षावधाद्धिगुल्मारुजतमारुजायजयः॥ ॥पिप्पलीकालमक्षीवकम

नंक्षाजकंतथालरुमतन्यदातंकुसक्षुद्धिनिवाजनं॥ ॥क्षीवजवन्यमाक्षाजक्षालमक्षासयष्टिं।
चूर्णंभक्षंजसंयुक्तंजकक्षुद्धिनिवाजनं॥ ॥मधुनाक्षिविषालहंमुच्यतजकक्षुद्धिहिधा ॥
स्यादुदाक्षिममत्रिवंमारुषनवनीतालिहतालाहितंक्षुद्धियंमरुरुक्षाशुयजमोषधंजकक्षु
द्धिं॥ ॥रुगनुकाविटंगनिवाजेनासरुषषतंपिवतक्षातसंमूलवक्षामक्षामक्षुद्धिनिवाज
नंक्षाक्षामक्षुद्धिं॥ ॥कनाजाक्षमिताक्षोद्रवमनाव्यपिभनकयं॥ ॥दद्यातंतुलाक्षायनंपीलावमित्र
भनकयं॥ ॥मुक्तेलाक्षालवंगमतिरुद्रमुस्तासमक्षंजाक्षामधुनालेहयद्यादुक्षुद्धिनिहिताकाम्य
या॥ ॥खदिरजखल्वंगेलाकाक्षमजीवंभजीवनाचूर्णंमरुतानेमधवा॥पित्तंक्षुद्धिरुजेयत्नं॥ ॥
युक्तारुजातक्षायाक्षामाषमायुजयरुतक्षजीततायानुवानयानंनशीघ्रंक्षुद्धियंयारुजं॥ ॥क्षुद्रायघा
मिंतीचूर्णंताचूर्णलाक्षारुल्यसमंक्षिकोकायक्वाजचूर्णंमधुवाल्कक्षाक्षुद्धिनाशनं॥ ॥कंजीवंकालम
क्षानालाक्षायधातुमाक्षिकंक्षीद्रंकरिमितायुकंगुडिकांरुक्षयरुतायक्षुद्धीतासजमनंविद्यमनं
वविनश्यति॥सद्यदवाक्षयंयाक्षकंजषनाजाचकासमुता॥नाजाव॥ ॥वातिसंचनकंक्षीद्रंपिप्पला

नागकेशरं॥ मधुकाम्रकजालरुक्षाद्यैर्दिनत्रयं॥ यवान्नकामृतानिम्बानिंधान्यचंदनमोद
पयस्याकल्कक्वाथवरुणत्वक्क्षुद्रैर्दिनत्रयकं॥ रुक्षामृतिपुनर्नवदारुव्रततरुंयवं॥ यवान्न
कायधूमं॥ कासभ्रमशिरोरुक्षारुक्षाविल्वमत्वारुधागस्तमकल्पेवरुयाक्षुद्रैर्मृदुपत्रवा
ठा॥ रुक्षुपत्रालमार्जवंमधुकंनीलमत्यलंक्षुद्रैर्धीतकषायायंरुक्षा क्षुद्रैर्दिनत्रयं॥ क्षुद्रा
मधूकषायघृतिपत्रनाडिकसंयुतां। क्षुद्रैस्त्रिद्वीन्युसूदनीरुक्षाचैवमुखेति॥ वटरुगमसिताला
घुंयतिनंमधुकंधृतिपत्रेरघुलाभयतक्षुद्रैरुक्षानिवाजनं॥ क्षुद्रैरुक्षा॥ सशीजकामाम्रक
वृंगवत्सीवर्चलान्यक्षलमूतानिमधानिरुधानिवगंधनिधातानिसर्वसमयंनिरुक्षा
॥ ॥सकेजाकनजंकोद्रंरुक्षाशीजकदाडिमंगलहावानकंयरुक्षामधुकंशीजकुर्मांकंज॥ ॥
वल्लजारुंमधुकंदमूल्यलंसलाजवृंगुडिकाप्रकल्पयत्। सहस्त्रिलासावदनंनधाजिलारुक्षा
रुक्षामयनिसलजं॥ ॥दगसानंशजसर्दकोजंयक्षीमधुकंमूल्यलंनियतंनसाठ्यीनरुक्षां
मयतिदाग्रहं॥ ॥कोजंशंगसमाधाकंकोजंसिधूरुजवकोमारुक्षामूल्यवंगधुषातालुजमधा

नयनामयति॥ ॥पूर्वकेसर्यनंत्यंवरुक्षंरुक्षामृधलयाकुलकासहसंवेवयवलाजयंयवयं।
उक्षारुकसिंगिजनपिवत्यादशमाचजग॥ वातजंगरुषाद्यंकंकिंशुलामवंधना॥ ॥रुयाल्किंत
कोजंजलीनिहन्यंतं मांसादेकंवाथमधुदकंवारुचैनंजावलिखनंजयरुरुयारुरुषाक्षुद्रैकंगास्तु
रुक्षारुकयंविनासंवेगलाऊरुक्षा॥ रुयरुक्षायांदुग्धंजलनालीसजलं॥ ॥क्षामस्यालवयुंना
ना॥ ॥हतीकपियलीमूरुयमानोधान्यनागजे॥ शितंमधूंजलपातंपियासाजंजभानयाव्यं
भुलंवकानंक्षवथंदीयनपावनंपीनसाध्यभूलंक्षंवसिन्धुकिंजपत्रं॥ तुलीवाकर्वंगं॥ ॥
सितामधूकामृद्वीकाभवितामूरुरुचनंरुक्षलाभवयंवाजंजंक्षीकोजसंयुता॥ ॥चंदनं
वालकागंजवर्यंठंमलयारुवा॥ दुजालरुरुयलान्यवरुकासजंकंगा॥ मांकिकनावलना
वलरुयंरुक्षादारुनिवाजनं॥ स्वलायंचंदनादि॥ ॥दुजालरुरुयंचंनागकंगजंक्षुलामधू॥
रुक्षापिरुहिंयारुयरुजंगिकंरुयत॥ रुक्षायूचीमयंकीघनलेरुतंजलंयदामजंघंदार्घ.
जागंवाप्रायूयात्रुखिजंतंतत॥ ॥स्निग्धंरुंतथाम्लंलवघरुकंगुचैनंववामुरुषंकजाति।

क्वाथं विधिहेवाधिजंरुषाकुं विवर्द्धयन्निःसाद्धमाशुः॥ ॥सकावगमलामनयःसलाजा
नाःखदेहायजनानिलांशाशीतानियानानिवगश्चयन्किसघीसमूक्षीसहनिकाजघानि॥ ॥
कालमक्षोषधेभीजकुजजंभीतवल्लिधाचीलामूक्षीजयलाद्वाहरुक्षाम्यामधूसंयुता॥ ॥महीष
धम्याद्धजायूक्षजंग्रन्थिकाहेवंपित्रक्षधार्यंतंक्वाथमूक्षायाकरुमदयूवः॥ ॥यिन्द्रमामलकंयि
बाज्राक्षायासहुसंयूजा॥विश्वहेषजसंयूकंमधुनासहुलहुयः॥जनाद्यःभाग्यमूक्षोवक्रासख्यासं
नत्थेवव॥श्रृंजनान्यवधोताश्चयूमयूधमनानिव॥मूलाहिस्कादनंधास्तोद्रुधोजानखाकुंग॥लुं
वनंवगलामाश्रूदनेर्द्धानवचाग्लायुकाचनत्व्यवहिताकुस्यावबाधनं॥पिवदुजालयक्का
थसच्छंतुमनासनं॥ ॥जनावेजीवलामूलज्राकासिद्धंपिवत्ययः॥सासंतुंजमनाभायवीर्द्धवाधा
लकस्यव॥ ॥खर्जुंगमधूवंदाक्राक्षाभार्यसहलूकंकासयूकसर्ज्जंगजयाधूतासमिताम्बिताः॥
लिहल्लोज्वयतायाहुममूक्षामयावहं॥ ॥उत्पलंकालमक्षानिलिकैकंतायनापिबयताक्षी
रामधूसंयूकंहुममूक्षोजजावहं॥ ॥लुधीलंपर्यटंधनांप्रबयधीतयाविधामधूनासहुपाः

यंवहुमनासनमूहुमं॥ ॥वासादुग्गालशाबूर्द्धनवनीतनलहुयहाधाक्रेजासहुसंयाश्चऽमः
नासनमूहुमं॥ ॥संन्यासंन्यासयश्चकाक्षीहुतामृतायमाश्रात्वाधोर्द्धमूच्यातंगाधूंमूक्षासयश्च॥
हुलक्रियां॥ ॥जाक्षामधूकमधूकंलोध्रकाश्मर्यंनाम्बिवामूक्षामलकक्षावजयश्चकंजयश्चका
श्चमधूमलवन्द्रनागंत्रनीलोत्पलहुलूषकासनोक्रिमावाजाक्षादिग्नाकुसुमवासिसंयूकामधू
सिताताऽऽयस्यानिलापिहुं॥ऽजंमदास्यंस्वाद्धिमूक्षायाहुंश्रमंतुमंऽऽद्धंगात्रकापिहुंक्षीपिवा;
साक्षामलामपि॥ ॥जाक्षामलकंक्षऽजंहुलूषकंजसनवाकल्यंयहुंयेघन्येषांहुमान्धविवि
धान्मकानापिक्षाक्वाथनसंसिद्धंघृतंक्षीरेसनवासर्पिकल्यानकंवापिमदमूक्षीयहुंपिव
त॥स्वाद्धिमूक्षातिसाजंक्षमंपूगहुलाहुवं॥सद्यश्चूर्णमयंखातुमात्रकंवाजिभातलं॥ ॥कंजाक्षा
कंपिल्लहुलदाडिमंयानकंयातत्यानांविडुमहुंमधूंकंजाक्षां॥ ॥भलावजीसवृंधीकंयक्षी
कल्कंक्षगुंचूंपायंयपुनर्नवाक्वाथेयक्षीकल्कंयमाधिकंगद्यपूपिकंजंयानातंसंयेक्षयानहुंना
जसं॥भलावजीद्यं॥ ॥द्वयंक्षसूनान्विडुंतंबूवंबृतंयानंविडुंमधूंखंखिलंधाजाक्षंहीना

हरीद्रमतिशीतमसान्यदारुकेलयरसयमतियानरुतंयजच॥ ॥खालिनीलाधवयाम्यरुमः
वज्रकंठनटं।कालायकरसगावतंभर्कुंयलयनं॥ ॥वचनंयदाकिंजल्पाउशीरंशीतवाजिधापि
वच्चकेनयायूकंसनदारुजायहं॥ ॥मधूकंमधूकादायनीसाल्यलमधूत्रिका॥जर्यतिमधू
मांयस्यांलीयुदारुजन्मान॥कासास्यकिरुवंमयंच्यासहिध्मावमीनंपि॥ ॥स्थाकिकाकूरुमः
श्रिंखालाक्षामूर्वानिलभषध्यामृतकंसाधितंतैलंमर्यगवारुशीतजित॥स्थाकिकातैल॥ ॥ श्री२२
कृमादिमलघ्नीहःजीवकाधनसाधवंतैलघृतम्यादारुद्वंयातापिहविनाशनं॥कृमा
धंतैलं॥ ॥धातुक्षयाक्षायादारुधनमूक्षोल्वानिशाकामस्यहःक्रियाहीनहःससीदहिभयंति
तंगामम्भोहिघाताजायंतिक्षासाध्यहःसकमामहःसर्वनवबवक्रौम्यूहःशीतगात्रहःस्यवाहीनहः॥
॥ ॥यच्चोयदिध्यतकिंवितमूयस्मागयाकिंसतउन्मादतत्वकलुयंसामान्यदाषदूष्यायाः॥ ॥
धूषघीत्रिरुलाहिंगुषडूथमासमसर्षपैः॥सानिम्बयत्तैलमूनेहःकृतवान्सकमाप्यिषा॥तंमूर्तणि
युल्वायानंनस्यार्थंगयूतद्धितं॥ ॥नकमालाजिजीघत्वाभूलंधूषंरुलानिव॥तद्वत्कपूयाहः

ल्याविल्वमूलंकटुत्रिकं॥हिंग्वैरंड्यवसिद्धार्थलसूनामलकीरुलं॥नावनाख्यंजनयाद्यंवरु
मूर्यंगुडतागवाःनहिजवद्यांसिद्धंगवामूत्रंचतुल्यंघोरंकाग्रहानवात्रयोगःनानाख्यंजन
नावनेः॥ ॥हरिद्राद्वयमार्कक्षामिसैन्धवनागरैःहिंगुपिप्पलीयुक्तिकटुत्रसानस्निग्धलाः
वयाःयाःलांक्ष्येतकटरोहिजीवकसूमर्द्यं॥तन्मूत्रयापिकंसिद्धंनानाख्यंजनयाहिनं॥ ॥
वस्नाम्बुपिष्टंसैन्धवयाक्षमंजननावनं॥ववाविषिरुग्धर्द्वीक्षनस्यापिवक्ष्यते॥सर्षिष्या
नादिमद्यस्मिंरुषद्यमवाग्रयते॥ ॥जिजीषनकमालानांवीक्ष्यलाघ्यसषयाः॥तन्मूत्र
पिष्टंजरिमूवाहिनंजंगनाहिनं॥चाकुथेकपमाजमून्मादंवनियच्छति॥ ॥हिंगुसौवर्चलं
शोभसषविषलीलंघेतादकंचतुल्यंघगवांमूत्रंसिद्धमून्मादनासनं॥हिंग्वद्यघृतं॥ ॥क्षु
न्मूत्रयरूनमूत्रयावाक्षीघनांसवलानजयाःजागर्त्रयाक्षमंदरुउन्मादनविनश्यति॥ ॥ह
तंजयदहिमूसक्षंक्षयहामवालिवृतंगाढंजागर्त्रयाक्षयंदरुतंयःलसमायानुवानस्नान
दयादहिगः॥ ॥गंगाक्षाविषलीमूलंध्यासमलकसषयान॥तन्मधनस्नेहमाक्षीकःसषपि

ह्यायषिमान॥नावनालंगकंशषुविदधात्रयहायहान॥ ॥शिजीवपुष्पलसूनशुंण
सिद्धार्थकंववामंजिष्ठाजटानीकक्षावमुमूर्तेनयीवयत॥वचीहरिद्रेश्चयाविन्शुष्कासासपि
हानयनाऽहना॥सिद्धार्थ॥ ॥सिद्धार्थकंववाहिंगुप्रियंगुनटनीद्वयं॥मंजिष्ठाल्वतक॥
ष्ठीवगास्वतादिकंघृतंका॥निम्बपल्लवीजनकमालशिजीषयाठसुगाद्धंशुषधंस
पिएतंमूर्तेश्चहमुंघ्रासिद्धंसिद्धार्थकंनामयाननस्यवयाजितं॥ग्रहानसद्यानिहंत्या
सुविलंषादाशुजानग्रहान॥कुष्ठालक्ष्मीविषान्मादज्वरायस्माज्यापयेव॥सिद्धार्थकघृतं॥ ॥ श्री२३
रक्तंगलामवालास्किनिमोक्षंविषदंशविद्रानिम्बपत्रशाकदुकाभदनंवृहतीद्वयं॥
कायासास्फेयवाक्षामदवाक्षसर्षपंमयूरपत्रीवासहुषकनीसत्रामलं॥मृहाघृतक्षसू
तघृतंशिवांशुक्षयुद्धृतं॥धूपनार्थेहितंसर्वरक्तषुविषक्षय॥धूप॥ ॥स्कूलाक्षजटजतन
ठसरुघलहरिद्रानिम्बालुश्यतीवकमाहरयाति॥वरुणादिद्विजदनगदिविद्युतठसासाम्ला
ल्पाक्षवतीतथाग्रयादनाद्य॥ ॥पूतीयुकादपस्माजक्षुद्रनादीनिवृद्धिमान॥वातिकंवे

स्फोटिव्यायपोहिकंगुविजयने॥स्फोटिकंवमनंवायेनयस्माजमूषायत॥॥तीक्ष्णयुंजातिहि
मकसम्यकवाधनं॥सद्यःक्षुद्रदेरुग्यस्यादुन्मादहृतीक्रिया॥ ॥निर्गुंध्रुवंवन्याकनाव
नस्यापयागतऊर्ध्वातसहसानासामपस्माजमहागदं॥ ॥मनाक्षातोदकंर्यंवशकृतयाजा
वतस्यवामंजनंरुग्यपस्माजंउन्मादंवाविलषतया॥ ॥यष्ठाहिंगुवचायुकामात्रावलसूनाम
यमसाक्षामूत्रंजयपस्माजसान्मादनावनंजनं॥ ॥यःखादकाजरुकाभीसादिकनववाजंजय
मूपस्माजमहाधातंसुविशालंजयंधरं॥ ॥हलंपाक्षिजायस्यहदारुक्षादिनीतताःदमू
लीजलतस्यकल्यानार्द्धंचयाजयत॥ ॥पंचकालंवमंजिवंशिरलाविडंम्बवं॥कुष्ठाविडंग
हतीकयमानीधान्यंजीरकं॥पीतंमूक्षाम्भूनाचूर्णंवातश्लेष्मामयापहं॥मृपस्माजतत्थान्मा
दंमूलक्षीरंघीगदंवातकल्याणकंचूर्णं॥स्यात्मेध्यदीपनं॥कल्याणकचूर्णं॥ ॥
दंमूलकंषायनंयस्माद्विगुद्धनंचाकल्याणकंगदंहरेत्यंकल्कीरतानस्यंविषापह
स्फोटिव्याचयश्चीमानसद्यंयातिविकाजनुत॥मृपस्माजतत्थान्मादहृतीन्मादंतत्थैवच॥

निरूहितयानरुग्भीर्घनाम्नाकल्याणकंघृतं॥ दशमूलकल्याणकघृतं॥ विभीतकित्रिफला
कोलीदववाघेलवालुकेशिखिजानन्माहुलिबृहद्भल्लातकिवचिरंगुका॥नीलाब्जलेलामद्
रिरिक्षायनीदार्वीमकर्भरीं॥तालीसवर्णरुतीमालत्याकुसुमंनवं॥विडंगंयष्टयघ्रिकुं
डंवचनयकेशाकक्षेत्रसभेत्रंतेरुविंभव्यक्षारिगवचाचितुंबीद्वयलवणाद्यपक्व
वयाऊयत्॥क्षयस्मात्रक्षत्रकासश्वासमेधमन्यानलक्षयावातजकफप्रतिश्यायहृतीयकवमथु
काक्षयक्ष्मामूत्रकृच्छ्रविसर्पायहृद्रुग्वांडुपाण्डुमयान्मादविषभषग्लवृ॥ हृताप
हृतविलानांगरुजानामयत्तसांभर्मुखीघश्रवक्षानांधन्यमायुर्यत्यदात्यलक्ष्मीपाय
लक्षाद्धंसर्वत्रहनिवारणं॥कल्याणकमिदंसर्पिरुत्तमंपुंसवनंवृ॥पानीयकल्याणक
घृतं॥ ॥कषायघृतयूषास्यरसैर्मांसैश्चवालानभांशवितत्सर्पिषांचानर्थविद्यात्तद्रु
साविद्यंसक्षाक्षयस्मात्रहनिनार्शं॥ ॥यूषहिंगुलवणंवचावदूकंगहिनी॥
जिनीषनक्तमालानांवीजंत्यक्तास्यसर्षपा॥ लभमूत्रेपिष्टंरुक्मुद्वहिनताऊरुहिंगुंव

गुडकमतस्मात्रमुन्मादंवानियच्छति॥यूषहादिवर्हिया ॥मूर्शांकयष्ट्याह्रिंगुला वयष्टाहिंगु
साह्यलोव्याघमाषगवांमूत्रव भषरुवाल्हिहयापिक्कुलावतावर्हिमयस्मात्रयोग्रयत॥
किलासबूतत्थन्मादत्रजभूविषभषूव॥ ॥कापिक्कासाजेवामूत्रमूर्शांत्रयवासाथा
सव्याघवरुमूंघापिक्कावर्हिरुपकल्पयत्॥ मूयस्मात्रतत्थन्मादसर्विपूरुग्रहाबूदा॥विष
पीतानलऊलाक्षंषांमूत्रमूत्रमाथ॥वर्हिया॥ • ॥सिद्धार्थकहिंगुवचाकजंवदववायवसं
हिक्काहिंगुलाव्यताकरुहीत्यक्कदूषिवंशमांसीवचाहिंगुचलिजीषाजटानीद्वयं॥वस्तमूत्रे
धर्मपिक्कमतदपानमक्षेनं॥नस्यमालपनंवेवस्मानमूढेनंतथामूयस्मात्रविषान्मा
दक्कयालक्ष्मीत्रायरुं॥रुग्लयहृयंरुनिग्रहाजेवशश्वासपित्रानसिद्धम्वास्तमू
त्रायदर्पेकृत॥लभमूत्रलवितालानांवापिलानांगवामपि॥पिक्कानिलसमादघाद्रपस्मृति
निवर्हयत्॥ ॥शृंगीवचामरुनिम्बवाकुष्ठरुत्लेष्मरु॥मधुनासरुरुहायंधोगायस्मा
त्रनाशनं॥ ॥वाक्षीगरुवचावाकुशंखपुष्पीरुजवचायुग्मंधमूत्रमुन्मादंग्रहापस्मारं

नासनं॥ वाक्कायशुद्धौ॥ ॥ पंचमूलीपिप्पलाद्रजन्योः कटुकत्वाद्वायुकफघ्नीमधामार्गनी ली
नीकदुत्वाद्दिधा॥ सह्याकंटकारिमूलीवटपुष्करंमदुत्वालघु॥ पिप्पलीनिर्गुंडीब्राह्मीपर्णी
कायादोषहृतत्वात्॥ रास्नापाभद्रिकाकुंभीवृक्षाणिवृष्याणिवा॥ अश्वगंधामाषपर्णीकाकोलि
निम्बचित्रकंभद्रमात्रिवृताश्विदंतीकांमदयंतिका॥ क्षीरिणःपिप्पलीक्षीरमाक्षीकाणिनैऋ्यस्नु
षिषडंघ्रयश्च॥ माषकृष्णसहचरश्वेतजमूत्रैश्चात्मीयपंचगव्यैर्मिश्रितयाहैमरुहम॑
सूपायसंमांसरसस्यात्तथान्नादश्चयथाचूदत्रषियोगुणान्ब्याघ्रीगणेक्षीरिलायां॑ श्री२ग
रुडीमर्कांशुलक्षीरयोरुत्कांड्यांचोपथिकानिवाजनं॥ मरुत्पंचगवंधर्षं॥ ॥ निर्गुंडी॑
दलस्वरसनंयावद्गुडूचिगवक्षसूत्रैश्चूर्णितंनावनंस्यादयस्मृतौ॥ निर्गुंडीतैलं॥ ॥ मं
मूरातैलेतुवंकसंक्षीरंप्रवालितरुवंगनाख्यांचविल्वंधमयमाविनाशयेत्॥ ॥
श्लेष्मशूलवपस्यादुवृषंवातामयापहं॥ पटोलरुलकेवृषाद्वृष्यावातारुग्लघुगवाद्या॑
लकंक्षायुषश्चयजंवातंविनाशयेत्॥ मूर्यंगस्वदनंवक्तिनस्येस्तरुविरंवनं॥ ॥ पंचमूलीच

वलासिद्धंकाजंवानामयहिंवर्द्धमानस्यमूलानिवलाल्पधमसर्षपा॥ ॥ मूलसीतिल॑
मार्कवासीवीजघृतीषयेत्॥ कपोषूलयनंक्यात्तवातामयप्रयोहति॥ ॥ विल्वहिंग्वा
म्लतिलाकुलत्थसिंधूत्थकविश्वमात्रिवृत्पिप्पलीशुक्लनदश्चयुतंसुखांबुभक्षणोहंभ॑
यच्चवातं॥ ॥ वाजिवाह्यवलातिमुद्गमूलमरुषष्ठ्यश्वगंधगृध्रनखवाजास्थ्यश्वशृं
नासन॥ ॥ सरुक्वजसृजवाजृनागजक्वाथंमरुत्तिलमिश्रितंचमवनंपीतंदरुग
तिंठपिप्पलीवलान्वितंजरुक्षतीक्ष्णया॥ ॥ यमाजक्षीवलाजास्थादग्धमूलघृतंपयः॥पि
वेद्वातगदान्जुरुक्तिगदवृद्धा॥ कीटघ्नघृतंलभ्यंपिवेद्वासावरुंयं॥ स्थिल्यर्षूलव
द्मास्थरास्नैर्दिग्धवितामलः॥ मार्गंगूधानलंभ्यालुमालुमनूलामयेत्॥ मार्गंगूधवा
तं॥ ॥ विवत्कंजवीजानिवृद्धवातःसूक्ष्माभ्रुणीचित्रकयूकानांक्रियाजानिवाजं
नीकृक्रियावात॥ ॥ वृंगजधूमसिंधूत्थतैलमिश्रंचमद्यतःसुखवातानिरुंध्यात्सुचम्मस्थ
स्थिलंघत॥ सुकवातान्यसृक्भाक्क्रियाचवक्त्वाभरुषकंमूर्धिवात॥ ॥ हृदयानिल

नाभायुतुचांमिचान्वितंपिबेत्प्रातर्व्ययेननस्यगुणाम्रुमासरुग्॥ ॥दवदायूस
मायुकंनागजंपात्रेषितंक्षिप्तावदनाहमुद्धीत्वास्यमवायूयात्॥कदयगतवात॥ ॥
स्नुह्यरुवस्यकर्कंमाक्षिकायाश्चलंचलं॥सुजरीकलाक्षेकंवशेमक्षेजातंकृतावक्त्रंग
वैलयुतारुंयुक्तायस्यानिरुनेत्रागगद्यं॥कंधात्रूएकुलंवालंमथयामानिलंधाज
यूषायावेलपाक्षिनी॥कोवात॥ • ॥वलामूलंशृंगायामाते॥ ॥स्निग्धजजमूत्रकंरुक्ष
सीत्रागंचक्रानूसंकावंविषमक्रंत्रांक्षिमार्ज्यंक्रयंवनिवाजयत्यासुवांक्षिद्वेतजत्वाकायुघ
गनयुकंस्यावस्यात्॥ राजयित्वायसायाक्रसर्वेस्यांयययुक्तं॥ अथवलवालंकुरुक
ज्ञापिंडुगाक्षेवित्॥वेतजवस्ति॥ ॥यक्तांनयवात॥ ॥जकस्यघीनलालयात्रावत्रकंजक
माक्रनं॥त्रकाघ्रितवात॥ ॥मांसमदागतवातंसंवेजवानिगृहनं॥मासूमदाजितवात॥
॥ ॥वाक्यांकंजातस्यरुजास्थिमक्रंगतंजयत॥कंतकादितैलंयाजयद्वेगशनाक॥ ॥
शिवलाकंतकीनांचतैलपक्वामदंहितं॥मूस्थिमक्रंगतहनिक्षीजस्यानैनसंभयं॥मूस्थि

मक्रंगतवात॥ ॥यस्यविंमांसिकांतक्रंलमानिविषावयत॥मूस्थलागवल्लषकुवलानुयं
चकल्किंतं॥मूस्थिमक्रंयतवातंविजकाजानुबंधनी॥मूस्थिगतवात॥ ॥मिजागतरनिल
जालक्षिजाजागरुनीक्रियं॥मिजावात॥ ॥मद्यंवापिवतस्यांघ्रिंतस्यनस्यबुद्धिमा
नाविहतंनाभियंलाघुकूर्यादमतश्चक्रियाश्चरुक्षकंवात॥ ॥निगुरुस्थिगतवायोप्र
निमक्रनयाजित॥नाडीदंखोस्थिनीरुषकंसेंधवनसमन्वितश्चलंगल्भषगदनस्यंमनाक्षमा
नीवक्रकानने॥पादयाहवात॥ ॥जकावसयनंक्रर्यात्मूरुंवातकंठकापिवदजघ
लम्यादरुत्सूचीरुजवयाएकस्मिन्वात॥ ॥उरुस्तंभोक्रयुगरुमथवाधूमंरुग्णं
वयतिरुग्णंचपुरुषाक्षरुवरुयथापिवजाक्षरुलवनंपिबस्यादिमधापिवा॥रुनीवृतिरुनी
वात॥ ॥स्वंजपंलोकलापास्यविस्वंचीपादरुषिया॥पाददाहवरुद्धस्यांकाकूंकवातकं॥नि
जायधंयकृद्वीतयथाव्याधिचिकित्सितं॥ • ॥रुल्लाठकानांसिमूलमध्यस्थिरुमरुषधनुम
त्रयसावापिरुतमनाक्षियावयत॥नतन्नावेहनंकार्यंपादरुल्लीवनस्यत॥मूत्रिते

वृक्षाम्लवल्लीवृक्षाम्लघवनासयत्॥ रुक्षाढकाद्यघृतं॥ रवल्लीवात॥ ॥मूषतानकादिवा
तस्यवाक्षस्यदानिभिद्य॥मूलकवृक्षवन॥ ॥हिंगुपुष्करसमूलंचवृंवृक्षनिर्गुंडीकाथवका
त्थवकनागदंतीवंशलवणेभिर्हि॥ हस्तागंयाश्चमूलस्यवृक्षंचायनकृते॥ सतुदंडायना
नकाघनूसम्रुवात॥ ॥यिंयिंत्सितमिदंकृत्वाचूर्ण्यवातायतानके॥ संसृष्टवाषसंसृष्टं
कृत्वादनक्रियापथ्यं॥ हनिष्यादस्रगानाशंदध्यस्रंवचयाघृतं॥ मूषतानकमन्यापिया
व्याधिक्रियाहिता॥मूषतानकवात॥ ॥पक्वाशयोत्तानमूर्ध्वस्तिर्यग्विन्नविजयनंव
स्कारिसंप्रयुंजीतक्रमघ्नकृपकस्यच॥ ॥पयोभक्तोपुष्करजधान्यकानांसहिंगुसावश्चलसै
न्धवानांविदंगदन्तमूलकस्यवाक्षोत्थनमननाविधिपिवेत्॥ ॥माषकहिंगुसिध्मूलैः॥
लानिताम्रलघ्वक्षानिताक्षानगुडल्यवक्षारोत्थावाप्यवकाहिता॥मावादिः॥ ॥यश्चिकाग्नि
कघ्नस्तुंडीत्रास्नारोध्यवकैर्हितः॥माषक्षारेत्यम्लानेलंपक्वाशयंयथा॥माषतैलं॥
पृथक्पृथग्नवलवणैरुलापिवलीयविवृद्धिंतः॥देवमूलोम्लुनारुवाल्वजलाक्षवलानितं॥
वक्षारयलानिवंशेवगुग्गुलाक्षैश्चिकैर्नरस्येषमांसजयोनिसायासानुवातजान्विकारान्॥

धन्वन्तरेवैद्ये

सन्धक्षिमर्क्षान्वृक्षमिश्चानिर्यथा॥ लहवद्विगुंजनायवालोत्थालाक्षाम्लानय॥ दनमूलाम्लुना
नाम्यसक्षावानामुग्गुलुं॥गुग्गुलूवटकः॥ ॥गन्धर्वहस्तनदूषकमूलकमालपूतीकनिर्गुंडाना
यग्रान्मूलदयचाडालिलवणनसहादूषलसंकुलं॥ स्नुहयष्टयग्निपाठावत्सिय्यजसकृद्विदारुदयत्॥
नृनतयग्रलवनमूषदिमक्रियानलाजेषु॥यग्रलवन॥ ॥त्रिफलासैन्धवीदन्तीविडंगत्रिवृतासुधा
कार्षिकानिपचलानिविल्वकस्यरसेनवै॥दधीनित्रिफलाक्षौद्यघृतयुक्तंचरुग्णे॥विल्वकाद्य
घृतंतस्माद्विनकंवातनाशिनां॥विल्वघृतं॥ ॥जास्नापुष्करजाविल्वाग्निमंथसैन्धवलसङ्गा
नां॥कुष्ठाग्निक्षारयवत्वक्षीरैष्ठकाक्षीवातार्तिनाशनं॥जास्नाद्यघृतं॥उरुवात॥ ॥मूलकस्या
कषायनकल्केष्ठकाजयवुग्गुलुंघृतंचकृत्वातंघृतंवृषंमासविदारिनं॥मूलकस्याद्यघृ
तं॥ ॥प्रारभ्यमूलकयवशाकमनदग्धमूलाम्लवृषलानायवकोलकुलत्थानांकुलेत्थाद्रक्षा
निमेषंसकृत्पादलवणंप्रक्षिपेत्तस्मिन्नीवनीयस्नुक्षीरंकृत्वेत्॥तथास्वेदंकारयेद्यावत्कायदग्ध
स्यहि॥सकोशस्त्रीयषड्यूषेष्ठिकवलंवातनाशनं॥नरस्येयेहयाकयूषानाखंजनवाजि

षु॥दशमूलाद्यघृतं॥ ॥द्वाभ्यांमितियलाद्यतृदयानिदशमूलतः॥घृततैलवसावसायुक्तं पृथक्पृथक्
तं॥तद्भक्तव्यामिहायोघ्नरागतांद्वियुद्धनव॥ ॥अगस्त्यसतुलांक्वाथंदशमूलात्पथ्यतोसम्य॥
क्रमुञ्जसमादायतायद्वाद्धविषाचयत्॥वादलेसारकैतैलंक्षीरंचैवनागवलौ॥जीवनीयगणंसूक्ष्म
द्वाबलाजातलासूगन्धकं॥मांसाहूवर्द्धतालासुनलूकलेलवालूकत॥कषायंसमादायसर्वमत्त
पृथक्पृथक्॥मज्जिष्ठालाक्षाधवलार्कक्षतवान्मतौ॥सारकंक्षीरतैलंद्वाविधिनाद्विपा॥
चयत्॥अगस्त्यामिदतैलंरुजातनघ्नकासितं॥यानवस्त्रोरुक्षयंगनस्यंचैवयुसस्यत॥ श्री२८
सर्वोद्धाद्धिकवातंतथवातकफारुवांसंधिमंगनचैवसूक्ष्मानांसंचयेरुकानासं मं
मयन्नाविलेभ्यश्चैवशुंचयाजेनामं॥सूयस्माजंतक्षन्मादंस्नेहपकापतन्कं॥दंधु
पतानकंधाजंस्नेमवातसदागुनं॥हनुस्तम्भाद्धतोकपंकाधातावास्कं॥नेमथंया॥
धूमयंचैवसूक्ष्मेद्धसदागुनं॥नतरुलवनंधाकंनगानांगरुवाजिनां॥नाशयंत्यासूस॥
द्धेषांदारुनांवातसंरुवं॥प्रयागरुमिद्धिधस्यस्याग्रहोनारिधायत॥सूक्ष्मश्लक्ष्णंतैरुनि

1

यानादयनजंतथा॥हरुनाद्धुक्षमौवातोक्षान्नस्याद्दुगतंनथा॥पक्वाशयगतांवस्तिनिगूहास्य॥
द्वेकायिकं॥क्षागजाद्यंतेलं॥ ॥नमयक्षेप्यकंधूवनाचवकपूतिका॥वलघुस्यचमूत्राणिहरुण्या
पूतिकस्यच॥गवधकस्यमूत्राणितथसहरुवस्यच॥धर्षांपालिकामात्रंतैलस्यक्षेविपाचयत्॥
क्षारंचैवाचगव्यंवाक्षीरंदद्याद्दरुर्जुघं॥सूस्यपक्वस्यतैलस्यधूर्यंमतःपजं॥सूक्ष्मनावातरुग्ण
नाकरुजानांतत्थवचास्यायिधाजेनेषीवासायधमथपजं॥हरुत्कुलत्थाश्चमूलंयतत्थवा॥
क्षीरंरुदंका॥कासजार्यांहुजागद्धंशक्त्यभीक्ष्यंथक्षीद्धिद्यनजाथवरुगयाजंजीवृजा॥य॥
षांवापिक्षयाद्याधिरनंयोक्ष्यन्वदाजूर्घं॥सूर्द्धांगलगघुंवातश्लेषितमववाक्रियानयत्र॥
सूयनंतासांचैवयुयाजयेत॥गर्कंमध्यतोविविन्नवसूक्ष्मवर्तनयत॥एतदक्षवजंतैलंवि
धूनापलिकाहितं॥विरुजंतैलं॥ ॥यूमत्रधाचतनंतैरुगद्धाद्धिधाचयत॥दशमूलीच
लाजास्थाचयवक्षदसपलानिच॥वनीश्चवंक्षामनघुमाषयद्धीचकघुका॥एथकदशपत्र
नलाशनतत्थवत्रमधिश्रयत॥कद्धायसममात्रंतैलमत्रचायंयत॥यशस्त्रोदि॥

नकार्यनकुलपित्तुल्यरुजां॥ दवदाहज्वरवातमूत्रकृच्छ्रगुदाकामधूयष्टिकापिप्पलीमधूकैर्गा
स्नासूक्ष्मवर्जनसंयुता॥ चित्रकंपद्मकोशीरकुटंजाघुनरक्तशालिसूक्ष्मशिरीष
बालपत्रनिदायपयसा॥ सारुकाद्यंकमादायशीतंमद्यंविनापयसा॥ नातदधंगनयानेन
स्यकर्मानुवासनं॥ एरंडपार्थ्यग्रहीसूलसाल्वंवंकुधयासकृत॥ नवामंशुष्कवल्यंचरुनू
ग्रहसिजाग्रहं॥ वाधिर्यंकर्णशूलंचकर्णनादंवदायपयसा॥ सूर्यंभक्तंत्यजंतंहनियानादक्षि
गतंगतंतयकालायगतंवसिनिगृहंसर्वकर्मसु॥ सूनीतिवाग्जानंगमनूचलक्षिंगंच॥ श्रीरत
योहिकान्॥ विंशतिंश्लक्ष्णकोलंचयानादवायकषितं॥ गृध्रसीवातरुग्नंशरुजूदोषंतथे
वंचायनंजानक्षुकाश्वसुरहीनासयामियं॥ वक्षाचलरुग्यूंसकुस्नानसंभयं॥ प
मंजघातेलमेयंबलंवंशाग्निवंधनं॥ घन्यंवंशाकंजंत्रंवंशकालपिसाचितं॥ पंगुलंथी
वासयोपोल्लितसंवंधवनाक्षिजाकंघसमानम्बलीचलातनाशनं॥ कूकूपंमंजघातै
ला॥ ॥शुंठ्यंभमयमागंधंपिचुमंदकवन्यनं॥ कंम्होकाष्ठीचंभलीचमूचंनिंबियाचयत॥

पृष्ठा१

॥ ॥नतपूंकीश्वगंधयाज्ञलद्राक्षोविदाचयविंश्रावविषयहलंकांजंदलाचहुगुग्धेष्ठाकंकै
रंडमलंमालुकाविसाकंदकंमालतीयष्ठाक्षीवंजमधूकंशालिवाचयंवंशकंशीमवायूनंनेवंत्राक्षा
मांसरसाहरुणीद्वयं॥ बलावालुकाकंदलामूसुचंदनयष्ठाकेशापक्वंत्रकाभ्रयंवांशकापिहरु
गध्यं॥ हन्यात्यूष्टिवलंकुम्यो कषानांमांसवंधनं॥ गतीयानिविकांत्रंवृद्धाभाधत्रकंपनं॥
स्वप्ननापिरुषाठकंयोषानाथगनूवासनेष्ठ॥ अथगन्धाद्यतैलं॥ ॥कंकंठतनूघंसधा
यकल्यादस्यवाजितंतस्यमांसस्यकवीतद्यांवलनतीरुषक्॥ वृहतीकंठकाजीवशृंगीकंकं
टकस्यवा॥ वयंतानिकलंकाश्वरास्नामामलकीतथा॥ नणीपूक्षंजमूलंकंपंचमूलंसरासा
थाषडुघंक्षीरमाज्यंविपचेत्तमाढकं॥ तत्कल्कीकृतंदद्याद्वंशाद्यंचलमूलकं॥ त
त्साधुसिद्धंनिधायाथशुरुरात्रौनिधापयत्॥ तस्यमात्रांपिवेत्कालवलमुखेक्षवृद्धिमा
न्॥ जिघ्रेत्तस्मिंदुंडुंतत्रकाश्लायनामृदु॥ क्षीद्धकंगायसूक्ष्मांशुष्कांश्चसकासि
नांसुपानकावागनांस्नायुमक्षीयतानिलउष्णवातंनाशयेन्नाशयेन्नाद्रुगसंसय॥ वयार्द्ध

कोकुंजसाधिय क्षीरंविषमज्वरं॥मिरुन्यावंरुनायंवबलबधाग्निवर्द्धनं॥कर्कटच्यां॥ ॥स
ाधसकलवसामज्जीणनाद्यंजनवस्रायश्लेष्मरक्तस्निग्धानिवातंवस्नाधावाजघानिच॥त्रसा
ठ्यर्यासिरुक्षानिस्वादुमूलवधानिच॥वंरुनंयच्चतास्वेद्यंश्लेष्मंवातगामिनां॥स्निग्धंवृष्या
नारुष्यंदिनाद्यंबृंहणंवातपित्तनुत्॥मासमात्रंबलंवर्ण्यंवृरुनंवातनासनं॥क्षीरीद्विसकृतवा
ताघ्नीपत्रंवघोदयं॥शूनसफल्येवंरुनंकंपाध्मानिपित्तिनं॥युक्ताहिमन्यरुजनंवात
व्याधिर्वेनाशयत्॥ ॥स्नेहयानानिनस्यरुक्षान्यायिवनाडिन॥उपनाह्यंश्लस्य
नस्वेदनंवस्रयाद्दितं॥दशमूलिकषायेनमाहुलुंगरसानवा॥बलाचार्पंचमूल्याश्वक्षीरं
वातात्मकेहितं॥माषपिष्टकृतंक्षीरेघृतनवनीतेनसाधितं॥दशमूलीकषायेनमाहुलुं
गरसानेवाबलायांचमूल्याश्वक्षीरंवातात्मकेहितं॥माषपिष्टकृतंक्षीरेघृतनवनीतेनसा
धितं॥क्षीरमांसरसैरुक्तादशमूलीरसंपिबेत्॥बाल्यायंक्षननस्यंचस्वेदयेदुपनह्यमान्॥
पिबेदपूजिरुक्तायवाद्यंसक्षाराहितं॥मूद्धिंतिलैरुक्तंस्नेहालेपेवदिनाद्दितं॥च्यवन

सिंयसकंवक्षीरसकंतथैववा॥क्षीरेरसानानामुक्तावाहुवानयाद्धितान्यत॥कर्योत्पत्तिक्रिया
कस्यद्वातपित्तविनाशनं॥गिरसाश्चवनेकार्यंदग्धपित्तहरंहितं॥तीक्ष्णधूमपानंवयुक्तायः
सोवसर्षपात्॥स्नेषणालेपनंकर्यंनाशनंरुग्घेस्मृतायत्त॥मूद्धिंतैलंसंयुक्तंवमनंसंशम
स्यात्॥दारुनंचरसायुक्तैर्गिरसाशकभोक्तृषु॥ ॥रसोनंकेवलंतैलमिश्रंस्वादन्नगाया
द्धितंगाद्दरुक्॥तस्याद्धितंनासमूर्धातीर्घ्रवद्यघनानामिवायुर्वमन॥द्धितंवात॥ ॥
पंचमूलीकषायेनसुस्वाद्वम्लकृतायुतं॥गृद्धसीगुल्मशूलघ्नंसक्षौद्रंनियक्षति॥ ॥तैलम
लघुर्वावीक्ष्यमूत्रघृतविवर्जित॥मासमेकंयतात्मायंगृध्रस्यूरुरुजापहं॥ ॥तैलंघृतंवा
द्वेकमाडुलुंगरसंसचुक्रंसगुडंपिबेत्॥कफगुल्मशूलगृध्रस्यूरुजंहन्त्यचिरात्॥
ग॥ ॥विल्वमध्येत्रघुवीक्षानिपिक्षाक्षीरेविपाचयेत्॥तत्पायसकंहिशूलगृध्रस्योपशमौषधं॥
॥ ॥भल्लातंगविडंगनिम्बंपाठावाश्वगंधकं॥नलघुविल्वमूलस्वरुनाकंघकांजिका॥क
षायायूषकाथेतक्षीरेवंक्वथ्यसर्पिरं॥गृध्रसीरुंशूलरुंनिरुंविरंकालानुबंधिनं॥ ॥जास्ना

यामृषलल्वकंपंचकषायाधिगुरुंलुंठसर्षिषावटिकाकल्कारवादक्षागृद्धसीहरुं॥नास्तागुरुलुः
॥ ॥पथ्यावरीतामलकीरलानांशतंकोमनाद्यगुल्मोहरिद्रांवक्षनयुकंचपलंकषायद्रो
घोऽलघ्यास्क्तमकजातं॥मूर्छाविलंबंकायतंकषायंलघुपचलघुनगवलाहासनिवक्षा
यवलायदयातद्व्यानिसंचूर्ण्यलाक्षिकानिविटंगदकीरिलायुशूचीक्षयक्षुन्नागत
कांघघानीयत्यक्षयक्षुन्नजस्यनीचंहिसाम्बुपानाविचरोऽनानि॥निषेव्यमानाविनि
हन्कोगामनंघागनंदोगृध्रसिखंजताश्वाद्रीरानसूंऽगादिगुल्मंपाघुक्रिमानवा
तरुंजंवगंकं॥पक्षाक्षयागुरुंजघनास्यानाठंकिलावपातिमंत्रगवालनमीनागः
पातिमंमनुष्यंजवनकंयाक्षयतुल्यवर्गं॥स्नायुष्यकर्षविदधनिसंधःचक्षुष्यंलंघ्यंष्टवाविं
षद्मगाक्षनस्यसंधानकंविलेषागलोघुशंखःसकलंषुचेवावक्षाद्यासोगुरुलुः॥ ॥
पचतचूतांऽकंक्षात्यलसूनस्यशाखवाबर्षंचयाग्निकृशानांपलिकांविभ्यहिगुडा॥लव
घनाथकपिक्षुचलाक्षेवासूचतसं॥गृध्रसीवातगुल्मंवपक्षाघानिवाजनं॥लसूनादि॥

॥ ॥वाजिगन्धाबलाविश्वदंसमूलावकल्कितं॥गृध्रस्यांतेलमलघुपानवस्तोयाजयत॥क्ष्यग
न्धक्षतेलं॥ ॥द्वयलसेघवाक्षशुक्षाविल्वकंग्रंथिकानाद्यहरीतकाक्षीनिविंशतिद्वाक्ष
दक॥मूलंघजावाक्षयक्षंतैलस्यतैलयथादोगृध्रस्यूरुग्रलाहिसुखंवातविकारनुत॥सि
द्धवाक्षंतैलं॥ ॥दीघस्थानिमिषाकस्यपसकाथकल्किधानासिद्धंक्षीरंत्रिवर्षंवय
नस्थंच॥गृध्रसीवात॥ ॥वाक्षंलयालांगसकाथनाहुद्योतलाक्षितंविल्वकस्कायनस्नुपानंग
स्त्रीजमाचरत॥दिवास्वप्नंसमंतापंयायामंमैथुनंतथाकटूष्णंगुरुहृद्यंस्निग्धलवणाम्लंचवर्ज
यत्॥ ॥पूगाक्षयवजंधमलीवाताःभालिषद्विका॥शुनिषधुकंवेणुयकाकमाचीशतावरी
॥वासूकापादिवाभक्षंभक्षंसीवर्द्धलंतथाद्यतमांसरसंहृद्यंमाषवायवायत॥सार्ष्यिषव
क्षवर्षंक्षाक्षपसकावातलाक्षितासर्पिस्कलवसामज्जानांखंजनवस्तिरिष्टासुखार्थंसुपना
स्नेहनवातहरंसुपाचयत॥कांस्यवातांऽगसकांसक्षतेलवसायुतेदशमूलंक्षीरंसद्यः
शुलानिवाजनं॥पित्तिषकानिलंघ्रायतद्वत्कासूनसर्पिषा॥ ॥मधुकंसक्षकास्यंयलेपनं

वातव्याधिं॥ ॥वासागुडूचीवरुणंगुलानामलघुनेलनपिवक्वाथः॥कमघसर्व्वज्वर
मध्यलसंज्ञयदसृग्वातरक्तंविकाजे॥ ॥हरिद्रिवाजीजकंकात्थवातघ्नासनं॥ ॥गुडू
च्याःस्वरसंकल्कंवृघृस्नाक्वाथमववापयस्तकालमासयंसूयतवातव्याधिनां॥ ॥क्षी
रीयष्टातसीलाक्षाश्वेमानरलजवाऽरुणाक्षमधुकंवलापियालमववा॥गव्यघृहसः
वृषजंगजंकाम्पिल्लानांमूलंवलाजंकयायवद्वधामानावातासृग्गुविनिहनिकिंचित
यगुडामाशानुकल्पितमद्धगतंवुधामान॥ ॥गुडूच्यश्ववल्लीरिंद्राकालुगजसनः
वाप्रियंगुलायाजसयुकागुडिकाकाजमंमिलाःकृत्वन्मधुनालाक्षयमधुकृष्णियकल्कं॥
यावत्सूक्ष्मंहाधार्जस्काठंसर्व्वाजंजंगयंतातत्सर्व्वनाशयंत्यागुसाध्यंचवरुव्याधिं॥ ॥
चन्दनमधुकंसाधुपर्पटंजक्वचन्दनंगुडूचिनिर्व्वृत्तंमूलंपद्ममूलंवभार्गुकं॥उशीरजातमू
लीवरनगमूलसदानवं॥भार्जिवाभंकंगाल्वेवकषायंश्रपिवन्नरः॥वातरक्तंसशुलंश्रदा
हपिडाशयंकर्कं॥चंदनाद्यंकषायः॥ ॥तिलापियालमूलंश्रविल्वमूलंश्रवासंसव्यो

पयसापिवेत्पलाशगवाहुनः॥लघन॥ ॥तिरुध्मवचाकुष्ठंनांद्याज्जनीद्वयंवृलपथुल
नुद्यात्कैवातकंसहरेत्॥ ॥मूलंजातकटुकायष्टीगुणकल्कसमक्षिकांशंमूत्रपीतंजयतिसु
कष्टंवातव्याधिं॥ ॥घृतिरुत्रिवामूलानांकषायंवासमक्षिकंकल्कंक्षीरंहरेत्पयसाजिरं
गव्यंतिसाहरेत्॥लघुःसर्षपनिम्बंकैडिघ्राकागतिलाहिनं॥ ॥वंक्षीवीसकधर्म्मकघृकंशि
वापाठलक्ष्मीनाशुरुःजास्नाजाहिनिजाऽरुक्षंगवाघृतंश्वगंधासक्षाकंहरेघृवला
विरिक्तंकयुंकात्थसमांसपिवेत्॥वाहयूकरुकपाठियादयुगलंश्वदंष्ट्रकुलत्थंमथ
यूषंजंगंवस्नानंपावासुधाजंहरेत्॥मधुकाद्यंकषायं॥ ॥नागलंक्षिपलेषाद्यंवरुपलं
पचात्क्षीणपाकेनसंहरेत्क्षीरंघृतंमद्यं॥षघलंशंकैगादद्यात्पजाक्षंगलसाधितं॥
पंकदूत्रिस्रुगाघ्रेस्रुग्घृतंवाकसंमितं॥क्षालाजंरुक्षयःप्राश्याक्षीकर्षंघृतानगजंक
वालमवार्त्तरुक्षंक्षिगत्राद्यंगुलिघ॥कपत्रागमयरुनाम्बानागजंरघुतन्मतं॥वघ्रीमायु
यमीजंस्यंवलीयलिंगनाशनं॥नागरखंड॥यामालित्रंकंयामयाद्धितं॥रुग्यात्रवाक्षतान्

दावान् गुडूचीतैलघृतं॥ गुडूचीतैल॥ ॥बलाकषायकल्काभ्यांतैलक्षीरसमंपचेत्
॥सिद्धपुनर्नवाकल्पाद्वातासृक्षवत्कनूत्॥नखायनामिदंलक्ष्मक्षिप्त्वायानोपसादनं॥
शवनंवृंहनंशुक्रंशुक्रासृग्दोषनाशनं॥बलातैलघृतंसहस्रपाकं॥ ॥पुनर्नवासु
लशतावेन्द्रजुवकमूलंवृषभगृष्टावलायलशाजनकंचशुंठ्याठमेकृत्वासंपक्वप
चेद्धेनुयापलीवेवाक्षावथकोलिकस्यनाद्वल्लषनघृनठपचरुणा॥ग्लेतेलंकृतंचैव
घाढकाद्रवृद्धघृपलानियच्छ॥निकृच्छुघृस्थपलंगुडूच्याठपलद्वयंक्षपलंक्षयांति॥पु
लंतयेभूघधाचितेकानिसिध्यक्षरसातविंगकानि॥कर्षंतथामाक्षिकधातुघृपुनर्न
वायायलभवघृ॥घृपानिदक्षाक्षवतायभातस्वादनंनवकर्षमानकंच॥वातासृजंवृद्धि
गदंचसपक्रियदवेस्यंक्षथगृह्णसीच॥ंधागृष्टाणिकवासिगंऋतथमवांगंपवलक्रय
॥पुनर्नवागुग्गुलू॥ ॥यावशूकसूत्रवागूसिध्वंमूर्क्षकदूषिवृवायमानिका॥यावदीय
कानिलरूक्षेकंजिरवाद्वयविंगावितवं॥कार्षिकंसूमसघृंद्वयाजिंसंयुतंपूजवल

मूयसंहरिष्ठाननक्कांजाम्बदृषादियवषष्ठतांकहार्यंषिषियेनिक्षिपहुंठवातगकमूदगमृगाद्य
गंझारुवक्काविषमद्यंगदं॥चित्रकूकमाखिलाद्यंधनयंचित्रविल्वमम्बाद्यंवातघ्नं॥गृद्ध
सीगुडूकाद्यंमंदाग्निहृल्लिकाक्षाद्यंनिताम्लियानिच॥वरुणिभ्याधनीकाजादिवृद्धांगुडूकल
लकलमूलंतंदुलं॥मूलंपानयजिह्वागवाक्षीं सुधकाद्यंसूखदंनिजलयं॥शंकाद्यंसमगुग्गुलू
ग॥ ॥यवयंकोरंडायस्कंडलंचाग्निषजाढकांकृतवंगुग्गुलाठयावासम्बंधंमुविल्वषाठा॥ ॥जि
वविल्वामलकीरूलानांयवकल्कामृष्टिचतुष्कयंचाम्लायाढकषूक्षाधितंविधायपायावमि
ढंक्षवलाजयित्वा॥नलघुंलघ्वियलंविधायपियूषयंगंधकसंडुकाख्यायवयूजस्यात्रयलघ
यष्ठकाकावल्लषजापिचूघृतानिक्षिपत्॥जास्नाविडंगंमजिष्ठंकघवदंकीऋजनागत्रधव
वाग्रायवकंमठकालशमानभषांरागम्बिनिक्षिप्यानिसानयेत्॥लामवातकटीशूलगृध्रस्यां
कादृभीषेकानुल्यमांसिरुक्षंयथमंयुग्गुलूष्मृतं॥शिरूलागुग्गुलू॥ ॥शिरूलानिविषा
वातूदाह्यामूस्कातजूषकंगखादिजासननक्काक्षगुडूचीन्यूषयादयेत्॥हनिम्बनिम्बकदूकाकालि

जीरक ३ सर्जि ३ अजमोदा ३ धान्यकं ३ चूर्णं कृत्वा तत्तुल्यं गुडं दत्त्वा मर्दयेत् ततो गुडिका कार्या ततो गुडिकां दत्त्वा तक्रेण वा दधिमस्तुना वा सेवयेत् ततो नष्टं कोष्ठगं वातविकारं यकृत्प्लीहोदरं पाण्डुरोगं गुल्मं शूलं मन्दाग्निं विबन्धं च जयति ॥ शुष्कस्थूलान्यक्षीसमादायाविगन्धा गोतापत्र्यूषणं चव्यं चेति द्वयं समधृत्सार्यषा ॥ नवीकृत्य सूर्सं कृत्वा लिप्त्वा कार्हुं पक्वं लान्यिनं ॥ तक्रघृतैर्यूषघृतं गोगलानांगसेनवाजाद्यैर्जाद्यैर्वृंहणैर्घृतपानं भोजयेत् ॥ यथाजागं यथासात्म्यं ससर्यूषरसं स्निग्धं ॥ सकारुण्यया लेन वातगकं सूपाग्घां निहनिवार्यं तक्रेण क्षुद्गागमनवघनामिश्चेन्नहिन्न रसंघहन्काजिकाभूव ॥ कच्छी ॥ कच्छी गुग्गुलू ॥ गिलोयमाषकाहीन मध्यमाक्षगमाषकाद्गलक्षाद्वादश संख्याका ३ वाकुंचिकायां घृतेन ॥ संसर्जनं वातगुल्मेषु गुग्गुलोः कर्षं घृतक्षमं ॥ धान्यचव्यशुंठीनां मांसरसाघृतमाषया ॥ गुडूच्या गुग्गुलोर्वयस्थस्यादर्शसि दयेत् ॥ ७ ॥ मात्रावज्ञानागबलाबद्धवायुकमूत्रतः ॥ पुनर्नवामृताकृष्णावाजिगन्धाश्च कंकणं ॥ एषकवर्गः ॥

पलान्यक्षीक्षुचूर्णानिकाशयेत् ततदर्धं नक्तं जायूकं चूर्णं संमर्द्य दधि ॥ स्कापयेत्सदधिरक्षुमद्यशोधकसंयुतं ॥ घृतस्यस्कन्नवा लायां सूरणेपलानव ॥ तंरवादधिदक्षवेळा नांयथाबलियलानगवाक्षकंकयंकुंकोद्धपेहाम्लसमृद्धं ॥ वातपित्तकफाक्षा ग्न्यागमनन्याय्यतद्विधान् ॥ हृल्लासगातियूषबलीपलितनाशनं ॥ यागसागाम्ल तानामलक्ष्मीकानिविवर्द्धनं ॥ यागसागाम्लकृत ॥ ॥ बकवाबानूगंधर्वहिंवाषंयाप्यम् ॥ त्रिदोषजमसाध्यंस्याद्यस्यस्यूर्ध्वंयवद्वाग ॥ ॥ स्त्रोतसांप्रकृतिमनंवसिकेर्मीविज्ञानं ॥ विवृद्धयादयावा तैर्व्याप्तस्यविज्ञाधनं ॥ यस्यात्कस्यचिन्मनंनजंमाशुकापनं ॥ तत्सर्वंसर्वदाकार्यं मूलकृच्छ्रेषुवर्जं ॥ तस्माद्यत्सदाकार्यंस्वलंघनमुद्धर्षाक्षममकस्यधिक्कृत्वामृतंयजिलक्षितं ॥ रक्तंपूजाघस्यामाकंकाद्यवादालसाल याग ॥ जागलेलघुहरीसेभमकेन्थलवद्यैहितं ॥ वायसीवासुताजेक्षुनिषधुकद्व कुलकेगाभकेगलवल्लेयुकंक्षीद्रुभाल्यादनंहिषक ॥ कूर्याद्रुक्षमुदाधेकजंकल

रूलसर्षपैठा॥मूलंवायव्यगंधायामूलमर्कस्यवाहिषक॥पिप्पलीमूलस्यवामूलेरथवाद
वयागृहिताक्षीद्वसर्षपवल्मीकमृत्तिकासंयुतोहिषक॥गरुमूत्रादनंकृत्वायुक्तमक्षस
वयनं॥ ॥रुल्लाटकामूलंगुंजायक्षीपुनर्नवा॥पंचमूलद्वयंमिश्राऊषसक्तोनिवर्हण
॥ ॥निर्गुंडीरुग्गुलुंवापिप्पलीमयनागजं।ऊषसक्षीरपिष्टंवामूलंजसनंवा॥ ॥पिप्प
लीवर्द्धमानंवासैंधिकंनगुडंनवाऊषसक्षयंसक्षिगंधोजारूकारूकंभवंवा॥ ॥घृ
तंसागस्यतंदयात्ऊषसक्षकखरुग॥ ॥कर्कशीवल्लीदीप्यंजलंबायुवंगजं॥मूलंगंधा
वहेलेंगैश्चसार्षपंपचेत्॥मूलंकार्द्धमात्रयातस्मादूषसक्षाद्धितंपिबेत्॥कषायंतैल॥ ॥
पलालांपिप्पलीमूलंनागजादर्कषड्गजं।तैलप्रस्थंसमादध्नाद्गृध्रस्यूरुद्वयंहरेत्॥मूलंकद्व
जंतैलं॥ ॥शुंकतुंबकालसहिंगुंगोमूत्रेनुसप्तकं॥हिंगुंवाबंधनंपूर्वाद्वेभवंयुक्त
नतंनाथा॥तंतंठंकातश्चरुंव्याकंपीयरुंगुंसत्रयंगृधंपुंसां॥क्षामंमयाकृष्टिरुवाचिवाजा
ज्यनिर्गता॥कंपीमूल॥ ॥हिंगुंवयाविडंशुंठंकृष्णंशाजिसपूष्कजं।हात्मगुप्तंमिदंचूर्णं

वातंवातामकिंतरुग्॥हिंग्वाद्यचूर्णं॥ ॥वंशंमूलंनागरंमेषशृंगीकावृद्धवो४
क्षतचूर्णंमलालमालयातंचसामानलविनाशनं॥मुस्ताद्यचूर्णं॥ ॥मूलंवृषाभद्र
गेकंणिरुलानामगोमूत्राद्यंयत्थेरुंगंगद्वाक्षामाचूर्णंकुलत्थंसं॥पिबन्मस्तुसुरायव
कांजिकाक्षीरयवकंनवा॥क्षामवातंरुजंत्याशुसल्भंवातंजेद्धितं॥रुजांतकंदधाजाहि
४यसिद्धाक्षिरुलाकमाताप्रत्यर्कंतनवायूषान्रुगवृद्धियत्थेरुंगं॥मूलंवृषाद्यचूर्णं
॥ ॥मूलंवृषाभद्रगकंवरुंगंसपुनर्नवा।अजंक्षामंमुस्कंरकाकिलायसरुंद्यजं॥व
वांदजंपलान्नरागंनरुलाक्षेविद्याद्यत्॥तंनयावत्प्रषंनंकृतप्रस्थंविद्याद्यत्॥
गर्कंद्यत्तिंकदुंरास्नाभद्रगकंवलाचित्रकंग्रंथिकंमूर्सासेंधवंसद्यवाग्रजं॥रुल्ला
टकरुंगीतर्कीदंद्यवाग्पुनर्नवा॥हरितालंविषाग्रंथिदीप्यकाविल्वयष्टिका॥नषाम
रसमेकंतंसमुद्यांत्रिकामुष्किकंसर्षिमुल्यद्यवत्द्यद्यंगनीमृद्वग्नेनापचत्॥मा४
मवातंनिरुत्याशुसल्भेथंवातंजेद्धितं॥गृध्रसीकामलानरुत्याद्यघृतंविषमज्व४

जानाश्रीपर्णीक्षुरगोक्षुरबन्धुरुब्यादभल्लिसूदनंपोहनंवयस्थाद्यन्यागुल्मंरुग्यवक्षापिर्णी॥
मूल्यार्थविविधानागमनंनिरुग्यक्षीघ्रमवश्य॥वज्रवधूकंजंद्यग्निदीप्तिकंजंहिरुक्
त्॥मूलंवृषाद्यामिश्यवक्षाँकागाश्वगनव॥मूलंवृषाद्यंघृतं॥॥मोदिमन्कुस्थरागद्यो
यमान्यातद्यदवद्युरागमृद्याऽमादायानागगारागपंचकं॥दग्धोवरुणात्काःस्फुद्ध
वृध्नुकंमुरुं॥मस्त्रानानत्तक्षसार्ष्यिषाश्वदंनवा॥पीतंजयन्यामवातंगुल्मद्ध
ग्धसिंगान्गदाज॥श्रीहुनंग्रन्थिभूलादिन्लानारुग्यदंजानिवा॥विवश्वान्गा०जा
ब्रागमन्नृयक्षवंवस्फिंगान्गदान्वातानूलामनमिदंवृध्नुवेश्मनगंस्मृतं॥वेश्मनव
वृध्नुं॥॥मूऽभादमंजिष्ठपिप्पलीवितंगसूगदाग्विंवकंनाकाःसंधूपिप्पाल
मूलंरागमनंकेवेस्थपलिकाःस्यु॥शुण्दग्धपलिकाःस्युःलानितावन्निवद्धबाजकस्य
।पक्षपंजानिपंचासद्यानेवंत्रकाजयद्वृध्नुं॥समगुडवटकानरुग्यःस्युर्वृध्नुस्थाप्यूरुवाजि
ग्धापिवेतानस्यन्यामानिलंगाःसद्यंजागमसूकक्षाय॥हनीयात्तिहनिंचविभूंचिवन्यव

गूध्रसाजागमंगाकंविवासंगुदस्थूनंवेवास्किंवास्किंऽद्यथामीर्व॥अथयूसंथमंसंधिपूय
वाम्यवामवातंसंरुजा॥सर्द्यंयीतिनासंरंभन्नूवस्यंगुविध्वसं॥मूऽमादायमादकं०
॥॥वातांजिंतैलसंयुक्तंगंधकंपूगसंयुतंरुग्यंयूतंकल्यंपोषयोलाचिंरिषकं॥रुः
क्षयत्युग्रंरुजातंगूध्नुनायानूपानतंश्वासवातंकिंशुलगृध्रसीखंऽपंगुतां॥वातंऽकं
सत्मार्थंचसदारुंकांकूर्णाषकं॥श्रमयद्धतत्मादृक्सापिवेद्यविवर्द्धनं॥वातांजिगुगु
लूं॥॥व्याषग्रंथिकपक्षानिचित्रकंगंऽकद्वयं॥मूऽमादायमानीयद्वयांकाम्यूमवसु
ऽंलवंघानित्रयंकांऽसमंरागमनिकांऽयत्तांजिव्यानतानियावनिंतावन्न्यवहिंगुंऽ
लूंपादार्द्धनिर्मितंचांऽऽऽयदग्धवतसंगुटिकासाधितावातंसामसंधस्किंसंस्किं॥
दृढीकरातिरुग्वैःऽणंजानलदीपनं॥पूर्तिनादवदंवनंकालपादनंगमुना॥व्याषाद्यगुग्गु
लूं॥॥वृन्नागद्यमरुंकांक्वाथेऽस्कांगुडंऽसानतंश्वापंकंऽपंवाषद्यंऽऽऽंऽद्यःस्यावामवातं
रुग्वंसाजनीलरुं॥॥वंसाजद्यांऽसासिद्धंतैलमलद्युंपिवेत्काऽरुंगागरुंचैवसर्व

जागरुत्थजं॥ घृतसाधितं तैलं॥ द्विपञ्चमूलानि यो संरुलवधमूकाजिकेक्षा॥ तैलं घृतं पूर्वाभ्यां
करुवातामजिकं यान्॥ द्विपंचमूलं तैलं॥ ॥ तैलस्याद्विपलं वधात् काजिकस्य चतुर्गुणं॥ दशमूलं
मूलगर्भमूलं पृथक्पर्वचलाजिचाविवामदनयष्ट्याह्वशताह्वाकरुसेव्यं॥ विषल्यतिविषामू
र्कशास्फाकरुलयोस्तैः॥ मूर्कांगकैश्चतुर्लघ्वमकपीतविदकद्वा॥ तुल्याद्विपथमदयाः सिद्ध
निजाहृतांकितं द्विजीयवलीपवल्क्यां प्रयुनयं॥ शुद्धवातविकागुरुभारुषवृषघ्नम
या॥ कंडीरुत्याग्यपंक्षुमुद्गपर्ण्याकतियरुविदंधानारुगोषुपक्वेगास्मिन्विधातिभा॥ एष्ने
द्विजिह्वमत्रपूर्विकिंषुकंषवानमिरुवत्प्राकृतिवार्यासामरुगुद्धा॥ नियुक्ता॥
सूरिष्यन्यकजायवयवान्यगुडूचिछिलाविजनीयाष्ट्रयलनाश्रमवातार्दितेन्नेगाहस्ते
द्विरुममूर्द्धावरुक्षुलीविद्धवन्नं॥ जाज्यानकुजमानारुंकंठाग्न्यान्गुपद्रवान्॥ शूलीसर्व
वातविकिसा॥ ॥ तस्यशुलारिपवनस्यस्वदनवसूखावरुः॥ ॥ विल्वत्रघुतिलैकुत्वाद्रा
मयंक्रघनोत्रि॥ गुटिकान्मयखाशुशूलंत्वेवातिदुसजं॥ नारिलपाजयंकुलमदनष्ठका

जिकान्वितः॥ जीवनीमूलकंकावासेलश्यार्द्रमुलहृ॥ ॥ससेंधवाधावयुतःसलावस॥
हिंगुसौवर्चलयुतिमाद्यः॥ शूलानिजन्नकाक्षान्तिरुषुद्धिंघृतांविधान॥ ॥हिंगुयवा
विताधावचावसौवर्चलाहृया॥ वलायुनर्नवेजघुवृहतीद्वयंभेक्षजे॥ ॥सहिंगुलवर्णपो
क्षसधावातरुजापहं॥ ॥शुम्बुघरयाहिंगुपोक्षजंलवणंयंवयवाम्बुवातरु॥
लशुलापतनाकी॥ ॥विश्वभजघुंमूलक्काथयित्वाजलंपिवत्॥ हिंग्वम्लवेतसामल
कंयमानीक्षागारुयासेंधवनुल्यगं॥ चूर्णंपिवद्वागुडिमधुमिश्रंशुलप्रवृद्धंनिल
जंजिवाय॥ ॥सौवर्चलाम्लिकाक्षाजीमानेयीद्विगुणंहरेत्॥ मानुलुंगजसेंधवक्षागु
डिकानिलशूलहृत॥ ॥शुकाम्लवेतसयावयमानीलवणान्विकं॥ वाक्षपूजजसा॥
पंतगुडिकावातशूलनुत॥ ॥गुडेभल्लियवाक्षीजंसर्षिष्यानीविजयवं॥ जांगलानिव
मांसानिरुषर्जपिरुशूलिनां॥ ॥शिरुलानिम्लयक्षाक्षकपूवोजग्वक्षेश्रृतं॥ पाययन्
मधुसंमिश्रंवाहुशूलाद्यमक्रय॥ ॥वृहत्योभेक्षजेभघुवृजकाभेक्षवालिका॥

यालापिहरुवभूलसयाहरिकसूयागूधं॥ ॥लवघत्रयसंयुकंचकालसजामतंसूरया
सूनाम्नायाकुंकरभूलयुवायचरु॥ ॥श्लेष्मभूलाहरुजापयावंचकालेनसाधिना॥
॥ ॥व्याघ्रासिंहीरुलविल्वमूलंभजाहिदंतमद्धजर्कचतुल्यं॥नगभुमूलद्विगुघृ
रूपक्वापिवद्यवक्षारयुतंकषायंहरुकूक्रियाश्मनूगतंनिरुन्याद्रुलंनजानीकरुजं
वरुद्धं॥ ॥भंरवघृसलवघंग्राषंहिंगुसंयुताउश्रावकंनपातव्यंशुलरुग्क्रियायि
दाषजं॥ ॥विडंगयातिमजसंस्याषलवघानितंक्षीरयुक्तारुवंस्याशुग्रियाश्वरुवं
गुजं॥ ॥ज्ञमभूवासिद्धमधुजंत्रिरुलाघृसंयुताविलिहनमधुसर्पिस्यांशूलंहनिग्रि
दाषजं॥ ॥नलघुरुलमूलानिवृहतिद्वयज्ञजांपद्मिभूम्लसहदवावासंहपुष्पजं
वालिकाकुलथ्यातैश्भूतंग्रायंश्वक्षारयुतंपिवत्॥एथनकाषरुवंशुलंरुन्यात्सद्यरुवं
तथा॥बृलघुद्वादशकं॥ ॥श्लेष्मभुजक्रियाकार्यो करुशुलाविनासनी॥सव्यमाम
रुजंसद्यंतथाग्निविवर्द्धनं॥ ॥जसानमद्यसंमिश्रंपिबन्याद्यवकांक्षितंगावात्स्य

षक्तंशूलंनिरुन्याद्रुग्क्रियाद्यनं॥ ॥पलाशंपिरुलाजिष्ठंभतंक्षीद्रयुतंपिवत्॥पिरुल्ल
षक्तंशुलंनिरुन्याद्यग्निदीपनं॥ ॥पलाशंपिरुलाजिष्ठंभतंक्षीद्रयुतंपिवत्॥पिरुल्लेषा
ज्जयद्विदारुशुलाद्यमनाद्या॥पिरुकरुकवापियाक्रियाकथितापृथक्॥नक्षीक्षद्यद्यूंशी
तांशुलकरंपिरुत्॥ ॥हिंगुसोद्यद्वेलंपक्षाविडसैंधवंचुंवृभयोरुजंचपिवद्यूधृभृ
लयवाम्रसा॥पाश्वरुक्पिप्पलीनांभूलंनद्रावलानक्॥श्लेष्माश्मद्यसवाचगलजागे
वगस्यात्॥वरुरुमूगादिठ॥ ॥पुष्करंजानलविल्वानांक्वाथंसक्षीरजामठंयावंहरुद्यठ
वस्यादिशुलद्धाजूवृतेलवान्॥ ॥नजघुमूहरुतीश्चयंक्षापुनर्नवाभद्रकस्यमूलं
गावजीरुंसद्यदीवलावमरुसरुद्रवसरुविदाजीविल्वस्यमूलंसमृंसलाजानि
दिध्यिकाजीवकावर्षरुोवाकंश्लेष्मसाद्रासहदवपंचद्यलाषायंरुद्यादल्षं॥क्वाथ
नक्षीनपद्यरुधामानजसनतुलांरुलघुजकस्य॥उन्मूरुदो दोषायस्यस्याद्यस्यशुला
पमस्यातितमसर्षिजंदद्यात्पुसाद्यक्षिनिवाजनोसद्यस्थानगतशुलंसद्यनि

वणुविधं॥नजघ्नयामिर्दसर्षि ४कषूत्रयघपूजित॥नजघ्नयाक्षं॥ ॥यस्यनैवण्रमा ४
म्य ४स्याङ्स्यवसिकाविधेयत्रगनाजायघेनलनयसाजघ्नयूतनवा॥वदनावङ्साम्बूर्क्ष
षानाङ्गेजवाजूविकासंक्षसायङ्किक्षावशूलस्थापद्ववास्क्षा॥॥यायामभेयूनंमर्घं
लवघंकटुकानिवावगजावंशुचंक्षार्धं।वङ्क्षेयङ्गूलवादनजमङ्गूलिशुल॥ ॥युक्तवीमजि
वामस्कुपिवत्यक्कनवाजिघ्नावातयाभ्यानिहुंख्यासुस्यघ ४शुलनिवाजनं॥ ॥ज्ञागीधाग्नी
मिताक्षीद्विपिंशीतनवाजिघ्नापिङ्गवाभ्यविनाभ्यस्यावारुङ्गायङ्॥ ॥शूक्लाक्षि
पालीवृद्धूपिवदूषूनसर्षिषा॥मूथवावान्नमाद्यूनयाभ्यशूलानिवर्द्धयत्॥ ॥सौवर्चला
यवक्षारयावक्षरुजीतकीचित्रंकवातिवृद्धानिज्ञानमात्रासमाद्युकं॥क्षाजमूत्रंपिवत्सर्षि
४महिषानांविलेघनंगरुदध्नोतादरुयवयाभ्यशूलानिवाजनं॥ ॥कस्तूरीरुतर्भगंध
श्वेतसंरुलिवाजला।संतवर्म्मसमायुक्तंसक्षयूद्धानिकाजयत॥द्यूनालाक्षयीतून
याभ्यशूलानिवाजनं॥ ॥क्षाजद्वयंत्रिलवणंहिंगुयावक्षवृक्षजा॥यवाक्यूनावत्यीतंजय

नंशूलनाशनं॥ ॥मागल्येजघुयाशूलंरुजीतकाहवङ्गयाहिंगुसौवर्चलक्षात्यशुलघ्नंव
विजयवनं॥वैजयंत्या॥वायाजागस्य॥ ॥वकीवरुयूताक्षमाकिणाकटूकाक्षया।नालिकानाग
जंयूघृतैलमजघ्नवा॥युर्कविजयवनंसयवसिशुलनिवाजनं॥वसिशूलविजयवन॥ ॥
नागजतिलयुतकक्षंक्षयसासंसाध्यधूमानक्षात।उग्रंयजिघ्नमशूलंतस्योत्तिसपाजा
तिघा॥ ॥नंवूकङ्गंरुस्नाषीतंङ्गलनाशूनाङ्गघता।पंकिङ्गंविनिरुख्यनङ्कूलविषूत्रिवा
सुमान॥ ॥ज्ञंवूयाजूषघंवैवपंवैवलवघानिवासमंगमुष्टिकाक्षयाक्षजंवूकजसनवा
।क्षातरोङ्गनकालवारुक्षयक्षयक्षवलं॥शूलाविमूत्रातङ्गरुसहुसापत्रिघ्नमङ्गं॥ ॥ला
रुक्षघृवगायुर्कविलारंमधुसर्षिषा।पत्रिघ्नमशूलंभमयत्तत्शूलमाक्षयाङ्गयत॥ ॥कू
ष्मारुयालारुक्षघृंविलीरंमधुसर्षिषा।पत्रिनाभारुवंशूलंसद्यारुनिसूवाशूघं॥कंषूश्चला
रुं॥ ॥पक्षालारुक्षङ्गुणातक्षघृंमधुसर्षिषा।पत्रिघ्नमशूङ्गंरुनिवातापित्तकफसान्निकान
॥पक्षद्यलारु॥ ॥तिरुलालारुक्षघृंकुक्षीमधुकनवा॥मधुसर्षियुतंलक्षाक्षूलंरुनि

णवाषडंगमिहरुलाद्यसारुं॥ ॥विडंगपत्रकंवथ्यासप्तकंकदुकंघवनी॥खल्लाटपुष्पगवयं
चित्रकारनधुमिक्षुधा॥विल्वकद्वयकंजंबूमूलंपद्मोसपिप्पली॥सागमन्नकंवेसमानकं
द्धुन्नसमंसर्वमिनिकाजयत्॥यस्कंक्वाथकल्कंस्यधुयोक्तमार्हिकंशुरुं॥वर्षा०गोवद
रुंजीमान्सूपधान्यलपिप्पलान्॥तथूर्ध्वंपयसावांतंहनिशूलंसदाशुधं॥यजिनामसम्
रुक्वसद्यंगुल्लासमुद्भवं॥मूर्ध्वमूदजेत्तंमथद्यात्हानंसरुग्दजं॥पाद्यमर्यंनिरुन्ध्या
नुवृद्धमिद्धानिर्यथा॥विडंगद्यवृद्धं॥ ॥सामुद्रसैन्धवंकाजोद्यवंकोलमर्कावितं॥द
नीलारुजठविकंदंहव्यक्षनकंसमं॥दोषंभमूत्रपयसाभन्द्यात्वकपवितं॥तद्यथा
त्रिवलंवृद्धुपिवद्यूषनवाजिद्धा॥जीर्द्धुजीर्द्धेचरुंजीत मांसादिद्धात्साधितं॥नाडिशुलं
यकद्धुलंगुल्मद्वीरुद्धंवयत्॥विद्यध्यस्कालिकांहंतीकरुवातहरंतथा॥मन्द्यवंजंजः
लिहंमूर्जिद्धुंयरुनिगतैदांशुजानामविसर्वेषामोषधनाशोस्यात्रयजं॥यजिनामस
मूरुस्यविल्लषद्यनूरुस्थं॥मूत्रद्यादीनांद्यवंक्वाथुगुद्धं॥सामुद्राद्यवृद्धं॥ ॥

पिप्पलीक्वाथकल्कांसर्पिष्ठंक्षीरसंयवतासिद्धंक्षीरानूपाननरैहनिशूलंवसुद्विधं॥
पिप्पलीद्यं॥ ॥लोहस्यजठसाराग्निरुलायास्त्रयस्कथा॥गुडस्याष्टौचरागनिगुडात्मूत्रचतु
रंशुधं॥नतत्सर्वंचविषंयत्गुडद्यावविधानवित्॥लिहश्चैवतथावांक्षुलंचान्नयजिक्षय॥
लाहद्यगुटिका॥ ॥यवक्षारंजवद्यक्षुंठीकालवंथिकांचित्रकंपलद्यमानमादायद्यस्कंलाहस्यकि
ट्कांशमीद्यवद्धार्द्धिलवंक्षमूत्रावद्गुडंद्यवत्॥ततोजमात्रान्वटकान्याजयत्सकजत्रकान्॥
एकंद्यहाजनस्याद्यमध्यरुक्मधस्कथा॥सर्पिष्ठंक्षीरंजसायंजसेगोगलंजंशुरुं॥विनि
रुद्ध्यमूषिरुक्वशुलंवयत्रिद्धमजं॥सर्वशुलंगदान्श्वासूनाशयत्यवीर्यवान्॥सरि
मवटकाक्षषाणंजाजंहव्यकाहितं॥हरीमवटकमूरुठं॥ ॥नालिकस्यतायक्षरलवद्यान
पयूषितंविषक्षमग्निनासद्यकंयाद्रद्धमजंशुभं॥वांतिकंयोहिकंचैवश्वासिकंसन्निपातिक
॥नालिकलवटं॥ • ॥शिरुलामूलकंव्याषविडंगयुक्तंवचाचित्रकंमधुकंचैवचूर्णंभ
सूक्ष्मचूर्णितं॥यावदतानिचूर्णानिगुगुलासावदंवहु॥सागार्द्धिलक्षुंजानाजाद्धुहिमचा

न राज नांजी घ्नंसरुवंशूलं पाधुजागंरुलीसर्वं ॥ क्षामवातंतथागुल्मंश्वयथूंविषमज्व
रं ॥ क्षयायुग्शूल ॥ ॥ स्विन्नयतिनकषाघुतगुलार्द्धंहरुमाक्षात ॥ यस्कार्द्धंखघुगुलंगु
घवयामलकीरसात ॥ यस्कंस्यात्रिनकषाघृतंरसर्यंरुविषद्यंनद्रवीयायंगतंतस्मिन
घृष्ठंगुलंनिधापयेत ॥ द्रवंचलकघाक्षीरीगुणीनामजिवस्यच ॥ पंचलंतालासाधन्यार्कंपातुक्षी
तकंमूरुकंकषंयमानंघृतंयंरुस्यार्द्धंमाक्षिकस्यवा ॥ यंकिंगुलंनिरुन्यतंपाषाणयरुकंवय
त ॥ रुधंमूपिरुमूरुंवीकासश्वासमनायकं ॥ हरुलगकपिरुंक्षयरुक्षूलंवनाशयत ॥ रसायन गी ४१
मिदंलघुरंवघुमलकसंज्ञं ॥ क्षामलकीवघु ॥ ॥ मूलंवीकासनिर्द्धिक्षालालालोहास्र
ताक्षयापविघासशुलंश्वन्यर्थंकहवाःसंयुक्तानत्ता ॥ ग्रहणीयजिनासशुल ॥ ॥ मूनंघवाद्
ग्धंवित्थाद्धिंद्रयामहागद ॥ तस्याहरुयंघमनंपंचंयलसमाचरत ॥ कलाययवतामधम
ध्यामाकायालघवकाःजाजमाषाःकुलत्थाकंगुलालयश्चरुजनार्थंप्रसक्ता
यपुनाघास्त्रिंयंगवयवदधिसूकरसंक्षाजंगयमांसंसमाहिषं ॥ घृतंपुनाघवाभत्थे

वास्तूकानिम्बपर्तवः ॥ कर्कोटकालवेल्लानांपत्रानिसूरुरुचावरुंनिपत्राक्षानिकासमर्द्धय
लानिवा ॥ वारुघोहरुजेलोमत्यंत्रीकिलाश्मरीहरुलासरुगीहलाश्मसातजारसार्थेवापयपि
नाठा ॥ लिक्षाक्षणिरुलावृंघुंमयंयूंघुंसमायुतं ॥ यष्ठीवृंघ्नंनवायुकंलिक्षारुक्षीद्रनंजद ॥
॥ कल्काग्निवर्द्धमलमायसंचमूलारिषिवेरकंकोगवाक्षातंतेवासिन्यलसमंविपाच्य
निगूलघृंमंवविलीवकाल्पं ॥ मंत्रक्रिया ॥ ॥ मूनंवघ्यागा ॥ स्तरुस्थंघृतावरुंहन्नंस
मंयक्षमतामूरुमाकरुंरुजिकार्यंस्वप्नमद्यप्रयोवाचं ॥ ॥ वल्मीकामूलकरुलकर्जस्य
रुलत्वचंपिक्षामूलंसिद्धार्थमूतावरुंवलवनं ॥ ॥ हरुजितकीयवक्षारसंविनौलाजहलातथा
॥ क्षतंघृंमिदंयंमूतावरुंविनाशनं ॥ ॥ स्वघुवलंहरुगायासमूयकल्पाकर्षवृंघृंतंल
क्षीरायालेहजननमधुंविताल्पदवंलिरुसाक्षागनतमोदपूगाषपिरुकरुंचविनियाद्यं ॥
सूक्ष्मादव्यथाभेषंवृंघ्नंनागवकानागवृंघ्नंउदावरुं ॥ ॥ हरुद्रांतंवाजिकंक्षुंद्राघ
युलंगूपवंशकद्रमनंमतिमानउदावरुंजमूत्रजन ॥ ॥ रुक्षद्यगीतकीश्यामाश्वरुही

ज्ञाजघामीषयत्।वटिकामूत्रयोतासक्षाःश्रद्धाख्यानाहरुपिका॥ ॥मदनंपिप्पलाकदंव
यालेजाक्यसुषेवाश्गुडज्ञाजसमायूकंरुलवहिंश्वासस्थं॥ख्यानाहगुडभूलवत्सुमूल
कमवच॥ग्रस्यावातमूद्यावहंयाताथानन्नभम्यति॥ ॥जामंधूमविडंयामगुडमूत्रेद्वि
पाचितं॥गुडरंडूलसमावहिंविस्वयानाहशूलनुत्॥ ॥द्विपूहजाहिंगुवचासकर्कंसूवर्चिका
वेवविडंचचूर्ण॥सख्वाख्यानानाहविसूचिकाहिंङ्जागगुल्माद्धसमीजग्धेष॥हिंग्वाद्यचूर्णं॥
॥ ॥हिं॥हिंग्व्यग्रगंधाविडंगुडज्ञाजाहुजीतकायवक्षारमूलकर्कंश्यग्धहृद्रोगविबद्धमतथा
हृदजानाहविशूचिकास्॥हिंग्वाद्यचूर्णं॥ ॥नागत्रस्यवलंचिर्कंद्विपलंजूक्षितस्यच॥तिल
स्थेकंगुडपलंज्ञाजग्धेषुनयायतत्॥वातगुल्ममुदावर्तंयानिशूलंचनाशयत्॥ ॥सोवच्च
लंस्यगवंक्षातेमंयामूवतसंग्धसज्ञाजगमनंस्यादतहिंगुपंचकी॥ ॥स्वर्जिकाक्षारस
ताठज्ञाजकांतक्षापिवा।वातग्रहीलग्नमयत्तगुल्मंपवनसम्भवं॥ ॥पंचमूलीकषायनस
ज्ञाजघाजिलाज्ञंपिवहस्यत्रयोदानवातगुल्मंवमूक्षयत्॥ ॥व्युषाधांत्रिफलाधान्यचिर्कं

गवंग्यचित्रकैर्माक्षीकक्षयत्तंसिद्धंसज्ञाजंवातगुल्मनुत्॥व्युषाद्य॥ ॥रुपूषाद्यावत्थ्यी
कायत्र्यचित्रकसेंधवैर्माक्षाज्ञाद्यापाल्यालामूलंदाप्यकंविपचत्यृतं॥सक्षालमूजवंगसंसज्ञाज
दधिवातिसं॥तत्पज्ञंवातगुल्मघ्नंशूलानाहविमादघं॥यान्यलाग्रहणीदोषाश्वास्कासाग्रवि
ज्ञगान्॥पाण्डुरुक्षक्षुगुल्मंचयमतद्यद्याहृति॥रुपूषाद्यघृतं॥ ॥चित्रकद्यावासंधूर्कंश्यथी
कायसदातिसं॥दाप्यकंग्रंथिकाज्ञाज्ञीरुपूषाभव्यकेश्समेभादध्याजनालभज्ञघुमूलकंवजस
घृतंतत्पिबद्वातगुल्मानियोद्वेद्याद्यपशुलनुत्॥चित्रकाद्यघृतं॥ ॥ताहिजेश्मयूरंश्वकर्कंट
कोंश्वहंकान्॥सर्पिश्श्रालिपसन्नाचद्वातगुल्मायद्यात्॥वातगुल्मा॥ ॥ज्ञाज्ञापद्यस्यामा
घृर्कंपद्मकंचन्दनंमधूपिवरुघुलतायनपिरुगुल्मापशमनंक्या॥ ॥ज्ञाज्ञामधूकवर्षाभूंवि
दात्रीसभागावज्ञीरुलूषकानिरुहलासाधयत्तलसंमितं॥ज्ञलाढ्यंपादशेषंरसमामलक
स्यवाघृतंमिज्ञगसंज्ञीरंमरुयावत्कंपादिकंगसाधयेत्तन्घृतंसिद्धंश्वर्कंगाज्ञाज्रयादिकं॥
प्रयोगाल्यिरुगुल्मघ्नंसर्वापेहंविकारनुत्॥सारुचर्यादिरुपथ्यकृत्पादशेषंघृतंस्मृतं॥

धौतजातादिकृतं॥ ॥चन्दनमधूकजातीपत्रश्यामधूर्कासधवपिचुलतीयनपिचुलो
पमकल्क॥ ॥जलदशगुडूचीसाधनायमानांचतुर्थांशंवरणगयूर्जसूतंठकक्वेथसंयोक्ता का
र्षिकाणिगृहीत्वाकदुकामूलकुशायमानादुजालरा॥जाजीतामलकीवाजीजीवन्तीचन्दनमाल्लैया
नसश्यामलकानांक्षीरपयस्यावल्कतत्त्वयावलानिएथगक्षीरदलासथविचारयत्॥नाभये
पिचुलुमक्षवलातार्यक्षीजयत्तापिचुलुम॥श्यामलकीजम॥ ॥पिप्पलापिप्पलामूलंव
यस्थिजकनागजेतयलिकेसंयवक्षाजघृतवर्क्षविधावयत्॥क्षीजयस्कनतन्मार्ष्टिहनिगुर्म्म
कलासकंग्रहणार्यंजूगंवक्षीरुकासक्षयहं॥क्षीजबलकल्पं॥ ॥सेवाघक्षीजल
वघंदशमूलल्पं॥वारुगुल्मंऊर्ध्वस्यानुसहिंगुविउदालिमं॥व्याषाघंल्पं॥ ॥कलल्पक्षी
घृन्मालिन्यषष्टिकानाघन्यक्षीगलानामथंतलल्पंतंकंकरुगुल्मषूयाक्षयत्॥वारुगुल्म
॥ ॥यस्यतालिरुलादनीदशमूलपलानिनानाजलचतुर्गुणेपक्वाचउकीगभवत्लषिता।
सर्पिजघृतंतैलक्षीजयेकंसाधयत्॥सोमवल्लीमिश्रवासरुग्यानिगुल्मषूवाधंकं॥

मालिरुला जास्तावलाकदुकजाहिद्दी।विधिद्वितंगयाछीक्षरलिवातिगलारुका॥तंनयाद्य
वत्सषनक्षुतयस्तंविद्यावयत्॥यद्धत्यक्षनसंयाक्षस्धाकाजयलनवा॥तत्ताक्षतयलंदद्या
द्यवागुमद्धुमिजतं॥जीर्द्धसंस्यंविजिकंवरुजयजसरोजनं॥कदुगुलादत्वंगल्माथंद्या
द्धुमर्यक्षजान॥विर्द्धीरुानमानाहंक्षतमत्तद्यायाहुति॥मूत्रवावलक्काथनेवयाकमनीला
नोक्तं॥ ॥हस्तुकंजाजघाज्यवकापिलकवल्लिकंमसंधवाद्यंलपतंहविष्यकंतद
मक्षसि॥यक्षमस्मालिवलंषमूषुवीर्यानुपानवं॥सद्यगुल्मादत्वंधसीसर्षिवंतिग्रसंडुकाविं
दुक्षतं॥ ॥हिंगुत्रिकदुकवचायंमादाधव्याडगंग्यदतिमतिनिजीकयाभविष्यकवचा
सेंधवविडसोवर्चलयवक्षारयवक्षाक्षिकापिप्पलीमूलामूलवनसर्षपपुष्करजरुपयाजाग्रापथ्या
गासंवर्द्धमाकुलुंगमस्तनवदधियतिरुविताक्षमात्रागुलिकाःकाजयत्॥ततःस्नातजकेबां
वातजागीरक्षयेत्॥एषस्वल्पागंग्यमस्कासाजावक्षद्धागमद्धानंधात्यदत्वहिंगुला
नारुमूत्रक्षारंश्वाहयांजुगमनवरुलनिरूनाप्तिरद्धाग्यर्थमूयद्यूक्षनरुंति॥

हिंग्वादिवटिका॥ ॥मूषामार्ज्यलाभनांतत्येवक्षजकस्यवस्तूरुक्रियामाकुलुंगक्रटस्या
ग्निकस्यवातिलसर्षपलालानिदग्धारुस्थानिकाजयत्॥जग्रायिमूत्रसहितंसूक्ष्मितलसम
न्वितंग्राव्यूषदंपिप्पलीमूलंचित्रकंसूक्ष्मूलकं॥मूद्धीमातिविषांपाभंक्षरुरुस्नातवानिव
॥वयंपूलिकमंक्षंवतिलकंकदुजाहिद्दी॥क्षीक्षाजोपंवलवद्धेसमरागानिकाजयत्॥स्त
नापलवद्धेन्यूद्धंक्षनेमद्धग्निनाषयत्॥तदग्निवद्धूनिधूमंक्षेयावृद्धुमीतल॥जंगुल
ग्ररुमालाथसूजामंतनपाययत्॥मस्तुग्रनालमूत्रेमुयूक्षठस्याजागुलीक्षेत्॥गुलवा
तादगक्षीरुपांद्वामयकिलासकानारुन्यादाग्यलवद्यंग्रसंक्षरुवानूनूत्॥ग्राग्य
लवद्धा॥ ॥स्नूकपत्रतिरुलायावरुरुस्थावह्निवासुकांकजंगाक्षीवयानुंडीग्रहीकंवय
वयवदावं॥द्विपचैलंचवनयस्कंसाधयत्सूत्रमाहिषं॥मूनद्यूमयवदंवयावरुभंरव
रुतग्रावषनामास्तूरीजाजावक्षद्धानिग्मतंचूत्रा॥पंचगुलानूदावहंविदध्याद्यंवद्धि
द्धावह्निसादादजात्सैन्मद्धानिक्रियमषवयाहुति॥स्तूरीजात्रम॥ ॥वक्षोलमूल्यल

पक्वांकमूर्वमधूयष्टिकापक्वासूनावल्काथं क्षीरनाथ्वकार्यं॥ घृतंपक्वं नवंपीतंजकपि
कपिलासरुलमूत्र॥ दारुहरिद्राद्वयंदार्विनिशाभरुजेयजं॥ यकृद्प्लीहगुल्मघ्नं॥ • ॥ऊषुद्वो
दयहिंनांविधिजस्थदारुहरिद्रा॥ क्षीरियवृक्षमंडुरिक्षगुल्मनिवारयत॥ जकपिहरुजेयो
गे द्वीतीयेभ्यमगुदजे॥ गुद्वोरिर्ष्यन्धिवर्क्षनिजक्षन्नग्निवंलसदा॥ गुल्मवस्त्वनुपाना॥
नियथवस्त्वयाजयत॥ जकगुल्म॥ गुग्गुलूल्कादनीशंकेजासेध्ववंवा॥ कांक्षाजस
नसंपातगुल्महृदनमरुमं॥ ॥तालासमलाद्वयलंलवंगमथलानिवयानियान्यज्ञा
ख्यादिकर्षेचिंचास्वकवतसोवेराजाषदंग्रंथिकशुंठिवह्निमाचव्याजाजयवेकपलंपल
मरुतिक्तकीचापिपलंवयुर्धा॥ जितादिवर्षंचयुजे द्व्यूंवेमद्यादशस्यांगुलिकांयकर्यात
॥ गुल्मादजेभ्यसनशुलकासातिसाजरुत्वाघुमरुकामकृद्यमलाशंठाप्लीहृदयकृजे
मदाद्यमूत्रकृच्छ्रान्हरुत्वाभगुल्मभ्यथूकयरुद्रोगदाधान॥ ह्रस्वाद्यवन विजाजदाय
तरग्निंठहृदुर्ज्जया॥ वरुलासाद्यंठ॥ ॥ एरीवासजजेभ्यसेच्छद्यतीमात्रयाजीतांरुन्ना

हिरुक्षयादषूठंभाथवर्षेतिगुल्मनाशंघृतंविषासान्नविद्वषाग्निंहृता॥ ज्ञायतेदुर्ब
लत्वेवगुल्मिनामत्रघ्नयवे॥ ॥ गुल्मिगुल्म॥ ॥ हरीतकीनागजयूक्तनाकेद्वेजावेकयस्कालवल्ले
यवल्केठसाहेंगुरिठसाधितमत्रसर्पिगुल्मसद्दत्यान्वगदरनिलाक्षा॥ हरीतक्याद्यंघृतं॥
॥ पुनर्न्नवादारुसर्पंवमूलात्रासायवाकालकापिकवित्वपत्रकारुलनयवकोलमंथं
गयानानिलद्वंद्वघ्नं॥ पुनर्न्नवाद्यंघृतं॥ ॥वंवाजदरुआकल्कठसीवेल्लयलद्वयंघृतवरुं
ठलसिद्धंक्षुद्वागच्छसगुल्मनुत्॥ वरुणाद्यंघृतं॥ ॥घन्वमांसरसंक्षारंघृतंगलिकिरुशु
यतावातघ्नासिद्धंतेलंक्षवसिंदधिवत्कृतं॥ वातवृद्धागु॥ ॥श्रीपद्मीमधुकाक्षी
द्राक्षितायुतंक्षेद्धेमतापिप्पलीवसुक्षुद्वयसवयसंघृतंठगुलं॥ घृतंकषायायपि
त्वांक्षगपिप्पलिनाशनं॥ ॥क्षाक्षावलाक्षयासिनकंजारिठवंक्षगसंसर्घंरुका
लवेत्यकायाक्षिमायायुगडिवकेश्वक्षीजनसिद्धमहिषीघृतंस्यात्॥ क्षाक्षाद्यघृतं
॥ ॥कलोलूकाजवलंगवजंगुंजीवंमधूकंविषघ्याग्निंथसर्पिठयसाय

वरुं ज्रोद्रान्वितं पिरुं वामयर्द्धांकलालुकाद्यघृतं॥ ॥अर्द्धश्लोकाजमजिरुंछावलाकाम्भर्यावरुंछांयकेमूलंपथकयर्द्धपलाअर्षरुंकीछिजा॥पलिकान्नाधयरुंछांनसंज्रीनवरुंजुरुंधा॥कर्कैरुंछयुकषंरुकंसदाज्रीवनिःज्रीवयेत्॥अतावर्य्यादिमद्धीकाशर्कैः जाअवजाविषेशायरुंछिद्राद्यताद्वातपिरुंछवागशुलनुत्॥मूत्रकृछ्रयमहाशगश्मसकासहृयाधरुंआधनूस्त्रीमद्यरतांघ्रज्रीघनांवलमासदः॥अर्द्धश्लोकाद्यघृतं॥ ॥पिरुंछवागः॥ ॥कुष्ठशगंछयाजास्नाशुंठयक्षसपोक्षत्रोवृर्द्धूतावारुतांरुमूत्रे॥पातव्या वरुंछकैरुं॥ ॥शुक्लासागधामूलंयवक्षारंरुविषासरुंनाशयेत्पाशुंछवागंशुलानापि विनाशनुत्॥ ॥मूर्छालायन्यनाशीलयमानायाषयित्वांभावेलालकंदुकादाशुंछयोत्थ क्षसयर्यंठांपथलानिम्बषंशुमूंकांमूंछरानिम्बजिरुंका॥चूर्द्धोनायनिःशीतांक्षीरंशजा तिविषाममाशं॥तिकानामक्षुलाशुलंछसानियातनुत्॥तिकाचूर्द्धं॥ ॥सर्पंयलः वल्मयरुंछवरुंजासकालिता॥तिनिवरुंछायथलारुंमूत्रेलसंजासवेत्॥ ॥रुयासूंवता

रुंजाजासंजामंसविरुंकान्॥पिवरुंनालनालाख्यांसुंजारुंछनिवरुंछयं॥ईंजारुंछयं॥ ॥ पुनन्नवंदधुलतावंजाहिंछचूरुंकंभावंवलाभरुंदं॥हिर्पवमूलेनकुलत्थकनय वेश्मनायक्वाथितकषाय॥तैलंवलारुंजवशाद्यैरुंतैलवकल्कैंजवद्धेश्वसिद्धं॥तंमात यावाशुनिहंतिवीतंशूलान्वितंभाशुंजमूत्रकृछ्रं॥पुनन्नेवाद्यमिश्रकं॥ ॥खाक्षीविदा जाक्षगसद्यजेश्यकछ्रषूपिरुंछपरुंरुवषकाद्यं॥कंशकाशभजादर्छ्रंछ्रंक्ष्मेतिरुंछेमरुंवः॥ पिरुंकछ्रहुंर्जपंचमूलंवातविल्वाधनं॥ ॥वातास्त्रंछंयत्रीनंसदुंहंहिंक्ष्मायिनं॥ ॥ ॥ॐह्रींश्रींवंमधुकंमदांद्रीपिरुंपिवरुंघुलधावनंनादाद्रीतत्थंवामलकीजमन समाऊिकंपिरुंविनिहान्तकछ्रं॥ ॥त्रिकघुकंलघुकंभद्रंरुंकंत्रिकंछ्यजमन सिद्धंसार्पिरुंजार्द्धजयूतंवमर्यंकछ्रान्भजामूत्रविघातदाघ॥मूर्यंविलेषगपुनर्विलेषः सुद्रोग्रजीनांयवजंप्रयागं॥त्रिकंकार्द्धचूर्णं॥ ॥पिवरुंयातघुलधावनंनंयवालचू र्द्धंकरुंमूतकछ्रं॥करुंकछ्रं॥ ॥वरुंतधावनीपाभयकीमधुकालिंगकाधायनायारुंरु

यादिकल्कदार्वरयायहं॥त्रिदायकल्क॥ ॥सप्तपर्ण्यजगंधकवृक्षेलाधवठकजंकटजा
गुडूची॥साध्याजलेननिषेव्यवाकूपिंडंकवायंमधुसंयतंवा॥ ॥शुंठीगुडूचीजवाक्ल्क्यं
सक्षौद्रंक्षीरसर्पिषा॥धान्यामूलवत्क्षेपयामूत्रकृच्छ्रविनाशनं॥ ॥मुस्ताजठाकृष्णपिप्पं
मधुनासहयाजितांमूत्रकृच्छ्रंनिहंत्याशुत्रिरात्रंकृतसंभय॥ ॥मुस्तारुयाधववादामू
द्यानांमधूकस्यचपिप्पदकसमंकर्कंमूत्रदाहनिवाजनं॥ ॥शृतंक्षीरंमधुजठाकाजंस
र्पिर्मिश्रंपिबेन्नजठामूत्रदाहविभुज्यार्धंभुक्तदाघहरंपरंजठं॥ ॥विदार्याजीवंतिवाकाश्मर्यजी
वत्साद्यनानिमाकृच्छ्रपित्तनिलंहनिष्यतिजंबुधन्वमूलकं॥ ॥पुनर्नवामूलहरीतकीमू
लंगतावरीवलामूलंगंगाधावटपंचकोत्पलैः॥विदार्याजीवंतिकाक्षीरेणपिष्ट्वा
वजानुधाएधकदग्धपलानरागमनवाजिद्राक्षाविदार्यायष्टं॥तनयादावजेक्षुनस्य
स्याद्रोकंवंशवत्॥मधुकंशृंगवजंकद्राक्षासेक्षवपिप्पली॥द्विपलानांयष्टकदाक्षाय
वान्याकृतंवंतथा॥त्रिंशैःभंजेत्पलान्यष्टौतेलप्रस्थंघृतंपचत्॥एकदाघहरंश्रेष्ठंतैल
मेतद्घृतंपचत्॥

नेक्षुक्षीरेनापचत्॥तत्दाघजंपूगाधांत्रीकल्कंतनमनिर्दितं॥जाङ्गलजसमानाक्षरक्तकृ
पूतीयत्तन्नयेत्॥मूत्रकृच्छ्रकोद्भूतंमूत्रेणाग्नेरपूजितं॥मद्यंवंशघनूलंघृतंनिमूलंघृत
स्थतंत्यक्तानांचगुल्मानांवातलाधितकाश्चयत्॥वल्लजसायंघीतंसुकुमारकुमा
नकं॥पूतनेवाशतक्षीरेघृतान्यापितथपजंमासूकुमारघृतं॥ ॥कृत्वातावत्पथ्यंमू
लंकृत्वाग्निन्यर्द्धबलंतयारुवंतिमूर्द्धाचमूत्रकृच्छ्रंवदाजूर्धंमूत्रयत्नेन॥ ॥नलकृश
कालेक्षुसिरांकथितांपानंसशीतलांससितां॥पिबेत्क्षयंयातिनिश्चयंमूत्रगरुग्रहणा
नंच॥ ॥पिंडंकेकघृतंतावत्तोयेसिद्धंपयावारुघर्षंबमूलंगुडूच्यगरंसकृत्य
यावाग्लानेषुकृच्छ्रादिषुशस्यतं॥ ॥शृतंशीतंपयानाशीत्पूतनंतघृतंपिबेन्न
रंगर्कंवंशंकटंमूत्रकृच्छ्रातसंभवेत्॥शीतावरीरसंक्षीरंक्षउकृच्छ्रातनिवारणं॥ ॥कृष्णा
घृतंजस्यभवेत्तंसकाजस्यगर्कंगासिताक्षाजान्वितंमूलंवायसीतैलकल्पेयात्॥कांचिका
जसायुतंवासिंकंघृतंसिद्धंतुरुक्षवत्॥वासिंकघृतं॥ ॥क्वाथंसयवमूलस्यलोध्रजस्य

रुलस्यवापिवन्मधुसितायुक्तंमूत्राघातनुत्रापहं॥ ॥दववायुघ्नंमूत्रोपयोमधुरु
ष्णंतत्क्षीरंमूत्राघातेषुसर्वेषुसूजाकोजठरेऽपिवत्॥ ॥विदारीवृषकायूथामाकुलुंग
तैलुषकंक्षीरपाषाणदर्भेक्षुत्रपुसकाविसैरेनलगयेन्नेवावत्रायत्नायलाघवेतिवलात
क्षीरेकलशुचिमहत्यमृतामलकाक्षिजादयंक्षीरेक्षुदर्भमूलकुशकाससक्तुपे
वत्रायलघ्वन्नुसंस्कृत्यशुलप्रोथेविधावयत्॥यादृशेषयतिक्षय्यंतयस्तृष्विषा
वयत्॥यथास्कंधशाखंस्वसाधनसम्मितंगावंलंघक्रीडायामुत्कर्षकोन्याय
लानिवा॥यस्त्वाक्रंपियलाद्राक्षाकाश्मर्येसयूषकंवलादलालशाकोक्रंकमेना
गकशृंगीजीवनीयानियान्याक्षोदयेत्तुद्विगुणंघृतं॥ततस्तंपिबेत्क्वथंशनैस्तद्धिन
ास्यथागमूत्राघातेषुसर्वेषुविशेषात्विहरुग्वाशक्रीडासमिंगलेषूत्तीर्णयरु
षूवाहृद्रोगेपिहृद्गुल्मेषुवातास्थापिंपिहरुग्घृतं॥कासश्वासक्षीणरक्तंवनूस्त्रीय
जयेद्विषं॥हरेणुकेक्षुबीजंमर्कटंवेल्लजातीपुष्पंक्षीरेनाथाजाजंक्षाद्यंपक्त्वातत्क्षीरंपाद

नायरु॥यानिदाघत्रुटादावशुक्रंदाघेसजामयं॥ततस्तंपिबेत्कंठ्यंवाजीकरंघृतमुरुं॥पू
पूदंबलंवघ्नंत्रिदोषाऽमनाशनं॥यानरोगननश्यत्सूनक्षीरंपित्तेरुग्नतं॥विदारी
क्षुतामिश्रंकुशसायनमनूरुमं॥विदारीघृतं॥ ॥शुभ्रजीसूपकल्कंषुरुषर्षभंयस्यकांक्षितं॥
मूत्राघातेषुसर्वेषुनकृच्छ्रेदाघकालजित्॥राजनंबीजमांसंवमूत्राघातेषुशस्यतेमूवि
शेषेण॥विलंठमात्मगुप्तंचयंकूष्मलोकंतथा॥स्याद्वस्तीकूष्मलीरुतंहरुग्दाहश्मसंवत्व॥
॥ ॥वयूषस्यलवंलघ्वंशुंठीधान्यजसंयुतंयवकाजगुडंत्वाक्षंक्षयेत्पिबेद्घृतं॥शुभ्रजी
वातशानरुक्षीरिजकाजानुवल्लिना॥ ॥वीजयूषीरामलकक्षयकासवृक्षादनाकृच्छ्रमा
त्रंद्वावजस्यैरुक्षादुद्धृत्यक्षजात॥वस्कावसुगादकैठीजीवाकभरुदकंशुभ्रजी
नक्रीडाकंक्षुमायूवाहरुग्गदं॥ ॥यावाद्यरुद्यावसिजावसूकाभनकरुक्षं॥भावः
जीस्यंसाचेवरुग्णीकंकाजिका॥कायाग्यकाकुलत्थंचनाशीलाकुकुथवृक्षाद
नारुलूकंक्षयवयूषंभक्षकंरुलं॥यवाष्टकुलत्थाष्टकोलानिकृष्टस्यरुलानिवा॥ऊष

कादिघृतं वायुप्रधानं कफपित्तं॥ हिनस्ति वातसंसृष्टा सम्भजा क्रियमवरुं॥ वातबाधरे
वाघृतं॥ ॥नृसोपकुल्यामधुकाम्बरुदकीनाम्यर्धक्षयेषु काथेपिवदभ्रं
गुडगरुं सगव्यघृतेश्वाभ्रजिमूत्रकल्कं॥ वलादिघृ॥ ॥कल्कं काश्मर्यजातगुंदरुंकदासोजदाभ्र
रिष्टादशैविदारीजीवाजाह्वाशालिमूलंत्रिकंटकंरुंवंवाटलीपाभयरुंगोकरुंहिकापु
नर्नवाजिजीवन्त्यक्षीरिकाक्षपर्णिकं॥ एषांशिलाकंमधुकंवीजंत्रिस्नीवजस्यचांशपेक्षं
मूलादीनांवीजंश्चयापिंतंगुरुं॥ हिनस्तिपित्तसंसृष्टा सम्भजा क्रियमवरुं॥ कल्पाघृतं॥ ॥ श्री ५८
शिलाजरुंजिलारयंस्यात्खदिरंवंशंधवंकोसंधकंकतक्रख्यात्रिकंवीजकंघृतं॥पित्ता
भ्रजी॥ • ॥गव्यघृतंघृतादीनुगुल्मीरुग्घृतंरिष्टकरुद्रादिमत्रिवंत्रिकंसमसूत्रा
क्रियं॥ नीलिमधमांसंपित्तघृतंवादिगव्यघृतंवा॥ हिनस्तिकरुसंसृष्टा सम्भजा क्रियमव
रुंरुद्रादिघृतंनेत्राभासीगव्यश्मादिकाद्धृतं॥ ॥क्षीरंजातंवायुपयोनिक
षायानियंसिद्धंक्षीरंनानिघृतंवीतंवर्तिस्निग्धरुक्षनाशनं॥ कल्पभंजी॥ ॥वो॥

वासाघरिष्टघृतंक्षीरंकोरुवृकधिकंटकाजीरंकाकमूलं॥ दग्धाविवर्तकीजसंयुक्तं
मतस्याहिदनार्थंनिवलग्नभंजीनां॥ ॥स्वयंगुप्तावरुंघंशुंठीक्वाथक्षीरयुतंपिवत्॥ शर्करागुग्गु
लिशुलक्ष्मीमूत्रकल्करुंजयंजं॥ ॥कल्पाघृतंकरुंजमाहरुंयवक्षारंनिशायुतंवरुंभद्रवशुल
वमर्कंगाभ्रंजिनानें॥ ॥ ॥यंचमूलाद्धारवायाघृतंक्षीरंकोरुवंकथंदग्धपला
नरुंगमनुलद्धाल्पविषंवयत्॥ वद्धरोगंवलिष्ठंमनुष्यंवर्कंविषंवयत्॥ गुडू
क्षीवीजंवकल्कंकृत्वदायवत्॥ तन्निहंमूत्रयाषष्ठंशर्करास्यभंजीषव॥ सहसंरुंजनं
चैवत्रयाद्धंसर्पिगुरुं॥ हृद्यंचमूलघृतं॥ ॥खदिरसारमूलस्यवंशघृष्यतिर्कंकाल्
कायनंयवहेलंवल्लिनास्कंपनंनव॥ शर्करागाभ्रंजिशुलक्ष्मीमूत्रकल्कंघृतंपचेत्॥ वरुघृ
तेलं॥ शर्करागाभ्रंजि॥ ॥त्र्यूषणंजातिकामूलंतिलकंवेनकंत्थंवयानकंघाम्लनंपिल्लनंपि
लंपीनियकल्पं॥ क्षुभ्रंजामूत्रकल्कंचमूलाद्यंतंतथाभ्रंजी॥ ॥त्रिकंघृतंस्यवीजानिच
घृतंभल्लिकसंयुतं॥ श्ववाजीजघनंकाहुंपयसाभ्यंजिहृदनं॥ ॥पिंडघृतंमूलकल्पके

क्वाथयेत्कल्कसंयुतं। क्वाथयेत्तिलतैलमूलकल्कसाधितं॥ ॥मूलगयजयेत्क्षारं
पथ्याकालियकंकथाथदधिमंडोधिमंथैर्यूषमद्यैश्चभक्षणं॥ ॥
वमूघल्वकरुसपंजिकरासलिलतंचूर्णयावमूकयुतं॥क्वाथयित्वातुतावद्यावच्चूर्ण
लमायातिं॥तंयुक्तंकरुन्यादुदरामयमग्निंजीयात्॥ज्ञानंगुल्मवज्रलोघाकंकीचूर्ण
लोघ्रामांबयवक्षिगदानकल्कंकरुवाजंयाजं॥वह्निसादनसूक्ष्मचमग्नीयिसनु॥
वमूघयवचूर्णं॥ ॥तोजग्वक्षिमिश्रितंघनंसूत्रैर्घान्निग्धंमुखिस्कानंश्लक्ष्णंचूर्णनिजी
कांवमूघकंक्षिखादुलांग्रहयात्॥सगुल्कासचयुग्मुखसुविषयवादावल्लेषंजलात
गुल्मनगुल्मनवेदनंजरोग्घ्रयवरुग्नगं॥शखंवंयेनतागुंयवलाक्षयकमर्षंच॥
लांगुलंक्षीद्वीपंकवीजंक्षारंकघायाषाघरिक्षीलांक्वाथंचुर्णंवास्यवीजंकुनंजी
वारुकंसारंकरुनगादाजंवारयाक्षिमंजिचूर्णंकतानंजियत्॥यथासीवतिवाघर्जगुंत
मस्तयाक्षयमानंनंजगाखादनस्यसमस्कंदावज्रनिताम्भर्यंयथानिकृतं॥वमूघगुंत॥

॥ ॥कूलंसिंधूत्कविंगमांसंमत्स्यंकंजीलयावमूकं।वीजानिकुंमाधुकंकंभज्ञा
र्यादूर्तंयवरुद्यचूर्णंघृतायं॥दुःसाधुसद्यांभनिमूलकंमूलयाचंसमूलबंधं।व
तानिसर्वानिनिरुनिनाघंवसूदकाद्यवज्रघातं॥कूलंकादिकृतं॥ ॥वीजंज्ञांभरुदा
ज्ञिसंकल्पानाकंपंलाठ॥यज्ञादनासत्थंजघुरुलूवागीलवंबीभत्कंगवाहसजंकुर्घा
नलारयाकाकिलाजयाठ॥भतावजासर्वंकुंचसांकंठंचयवंशलाठ॥कंपातवंकंशावघ्रीका
भत्रीमूलसंयुतं॥नंठकाषायंठकंकौम्भंशंलंघाजविधायचयत्॥वातपित्तविकारंघ्रवस्तिंद
ढविवरुघठ॥मत्कंजाम्भिसुलघंमूत्रकृच्छ्रनाशनं॥वीजंतयघतं॥ ॥गुल्मिप्लीहाजी॥ ॥
ध्मानाकाद्यावाद्यालंधमानंधकांकुलंक्ष्याहिनायाद्यचूर्णाघमहिनांमदा॥
महिनांतिचसूकवानिनाभरुदरुकालेंगुंतभोलिपिंधनूजयनं॥विंडादध्याः
स्वादुनिम्बमूंजसनवारुक्षयनाधुनामासंयभहीयवंयिरुकं॥मदाद्यावद्यमूत्राभ्यंगमा
ठसर्वंचूर्णाकुंयाद्यवारुक्षमाद्यनसाकंयभरुचविलेषनठ॥ ॥तिकदुंफलामूलंकुंकुंकुं

लंचसमाक्षिकंलोहरजक्रोधसंयुक्तंकुष्ठिकंकात्रयदुष्ट॥दाषकालावलायकीरुक्षयश्चा
नूसामकी॥नवातुयोजिहागास्तिकेमकेर्यीयव्यक्तिनं॥त्रभहास्वातगाभस्थवातलोधि
तंभववामूत्राघातंमूत्रयावंयभहंचाशुनाशयत्॥लोहरजकुष्ठिका॥॥मधूमरुक्षमा
यन्नाक्षिवाहिरुथयोजिवङ्किनीयालोनाननतिमानत्वभरुनामूयावत्॥॥मिलाजग
त्रिफलात्रिरयाकंमहाव्याधिविनाशनं॥त्रत्रयक्कंक्षूमलघूक्षिग्धान्नेश्मक्कंजयत्॥लेभम्
त्रगाग्निनीलंवातन्युधनंयवक्षीतसाविनंमागजघ्रंरुतयाषदिनादितभाषिवन्मागो
यथानेवत्रद्भाविष्टंयथवलं॥ब्रह्मनजसमान्नतस्मिनज्ञाघ्नुरुजनंउपयुंक्तुलो
भवमभृतस्याभ्रजमानठायथाक्कमधूमहारयमक्कंजागसंक्कंजावयुवघ्नेवलायनभ
तंगावत्यनाभयं॥तहाविनक्कलक्काश्यक्कपालश्यविवङ्कयत्॥मिलाजकुयोगः॥
॥॥टंकुनभाठशागद्योभाय॥मिलायाछोमितायाक्षीवलानियलिकानिचाशुगाय
घनुगधक्षीवृक्षीकलमूलयाः॥याचुक्षीतयलंचयलाद्वासमधूघृतं॥त्रभहुलुक्कहा

न्यमश्वासकासक्षयाभजा॥मूत्राघातग्निमायथयुक्तंप्राहुचमाशुगान्॥ज्ञाघूक्षागा
विहगालहानाग्रमिलाजकु॥मिलाजकुलहः॥॥त्रक्षिनयवालूलौनिश्चठमठवाविषा
कंसमंजिष्ठेलाठकागुडूचनीस्तवन्धनोभजिः॥लाभक्षजकंसामवक्कंनिश्चयलोहरजा
यावयावामूत्रभक्षनोयादीयकंपूकनचेवलाल्वनामंजिवाविषायांकक्कंठकषा
यंठपचेनं॥वक्त्वातारक्षमरुविहकृतसाधयस्मार्ष्यं॥त्रक्षिनायंचनं॥॥मिलाजगुग्गु
लयाषविदंगत्रिरलासृता॥त्रक्षादक्षायाचूर्णनुमधनाक्षीखनाशनं॥॥विडंगनाग
जंजार्जकालसारुजंगामधुयवामलकंचूर्णनुठ्वयागठक्षीखनासनं॥॥वदजीपत्रक
लकनयायांजिकसाधितं॥क्षौद्यनूस्तास्मिन्मक्षंजसंवायिमिलाजकुं॥॥व्याषाग्नित्रि
रलामूस्ताविडंगेठगुग्गुलुठस्वादन्सर्वानजयच्चाधानमदठशेषामवातजान्॥नवक
गुग्गुलुं॥॥मूस्ताक्षेविवेस्तकल्मकंकालेंगपथ्यामलकानिगुग्गुलुं॥क्रमवृद्धिमिदंम
थनंविडकाक्षीखरगन्धजीरयत्॥त्रमृताग्गुग्गुलुठ॥॥चन्दनंकंकमांभाजत्रियं

गुडूचिलाचना। गुडूच्यागुडूकस्तूर्यौ कर्पूरजातिपत्रिका॥ जातीकङ्कोलएलामांसलवंगसाह्व
लानिच॥ नलिकानलदंकेशरनागजंभूनकानिच॥ नखंव्याघ्रनखंवृद्धित्रीघृष्टाक्षावालं
सदनकंतथा॥ क्षीरभल्लातकंनवनवंयोजयेच्चूर्णलवालुकं॥ सजलंसफलघृष्टलो
कातामलकीरसैः॥ लालक्रूर्चवकाकंचक्षीरकाकरसानिच॥ एषधुगीकंचशाकंसोमां सी
भानमात्रकैरमहासुगन्धिमिश्रणेलघुक्तनसाधयेत्॥ एषदमलदोर्ज्झकथुकरुरुजंघ
जं॥ भूनलायकरसंकुरुष्ठसकलिकापिवासुरावल्लीभुक्त्वा॥ श्रीघामदयनवल्लरुष्ठाहि
रुल्लादर्नलायाश्वगन्धाचमदाभनं॥ वंध्यापिलरुतगर्भंधारयेत्पिबुलायेत्॥ एषपुनर्नवा
प्रातिश्रीवल्लभत्रदांभनं॥ महासुगंधिलेहं॥ ॥ शिरोलातिविषामूर्वाशिरीषत्वक्वासवे॥
निम्बात्रयधवत्रुक्षासकवर्धुनिभद्रयं॥ एषुचाद्रुगवाक्षीकुरुसर्षपनागरं॥ लाभ
रिक्षामेवकंशूवसादिसाधुतं॥ यानाखंजनगंधनस्यवासेवृगाजयेत्॥ कुलत्थलाल
कधुदीनजयेत्कुरुतानगेतानू॥ शिरोलाक्षलेहं॥ ॥ वामादजगन्धालेपाक्षुधेयुधू

सूनयामाशयावालद्वयंपायामिदंरुचिरादनमूलषचलवाद्यं॥ ॥वद्यघीवलावा
घीलाद्यानागजसाधितंऊर्जापिप्पलीदशद्रजमितिपिप्पलीरुादशक्रियाश॥ ॥नागजंतिपिप्पलं
पुरुंद्यतंलतथाद्रकंमस्तनंसाधयेल्लावपिवत्सद्यादशायद्रुश॥ ॥विभल्लाष्ठभिखे
नादकीद्वद्वन्नीलारुलतयं।निर्भाविर्तगर्कमिर्लांमूत्रेघदजवानापिवत्॥ ॥यष्ठपिव
न्यातशुक्लायद्वयंचित्रकामिर्तंक्षिपंतस्यपुरुंद्यनमसाध्यमपियादजं॥ ॥आशद्रु
यस्यनलद्यषनीलीलवद्यपंचकंवृद्धिंतंसर्पिषायंसद्यंगुल्मादजायद्रु॥ ॥पिप्य
लावद्यमानम्वाकल्पादिद्वयायत्राऽऽनांविनाभायनाक्षितनसंशयं॥ ॥
मूर्कऊर्जयलद्यद्वद्वाऽऽजयलानिषद्॥पथ्यर्कपिल्लवंभ्यामाम्लयांजिवार्द्धिकाभ
नालानाद्वद्वादनकीभंखिनाचित्रकंनयाजाक्षाम्यालिकेकाजेष्ठद्यंवेदाविपाचय
त्॥सूयस्यमलिनंकाद्यविन्दुमात्रंपुदापयत्॥यावत्सर्पिष्यविन्दुनावद्यमाजिय
त्॥गुल्मंकद्वमुदावहेभ्ययंपुरुगन्धजं॥जमयंयुदराघष्ठीवद्रुमिंखाभनिर्यथं॥
वत्तविन्दुद्यतंनामयनाल्यकाविविर्यंत॥विदुद्यतं॥ ॥यमानीरुषाधान्यपिद्र

लासायवंविकाकाजवापिप्पलीमूलमङ्गध्यभणीवचा॥मताक्काऽऽजगंधायषद्यघृ
ऽऽजीसचित्रकाद्वीऽऽत्रापुष्कंमूलद्वंलवद्यपेक्षाविडंगंवसमान्यानिदंद्यात्रागं
तयंरुववतानिवृद्धिभलद्धिगुद्यंघृरुलाघाद्यनुदयंगुद्यं॥नषनाजायद्यंनाम
चूर्द्धंजागगद्यंयद्यंनेनंयायातिवेद्यंनंगाभिवृद्धिंवासुगाश॥रागद्यंघोगाऽऽकास
द्यंसंगलग्रंरुद्वाऽगयरुद्यागंकुरुमन्यानलंतथाविंद्यविषमूलेविषमृगल
कंहिमविधायथरुस्निग्धकाद्यनंयथमतद्विभेचनं॥नाजायद्यचूर्द्धं॥ ॥विदंगद्य
न्तिसिंद्धूद्भकन्द्यवाचिंतांपिवत्क्षीद्यंसंचूर्द्धंगुल्मद्वाद्रुदजायद्रुंपिप्पलीलोह॥
तंतायंमनारुष्यद्विदीपनंवातश्लेष्मविकाजर्द्धंद्भगद्यंद्वाद्रुनासनं॥यमानी॥ ॥विद्यवंशि
रुलादनीद्व्यंतायुक्तेऽसमंगयावद्यंतानिचूर्द्धंनितावन्मात्रेऽसमद्यवं॥शवर्यावंस्तारु
ऽऽत्रत्वक्पद्मपुऽऽपेरुतगाद्रुल्यकंनानूलिकंवपुऽऽपेजातयद्यंसि॥सदर्द्धंगुलतेऽद्यो
दनंगुमदनारुषवंकायद्यंद्वाद्रुदाद्रुनिभुलपाद्यामयादिकं॥सविंतांग्निवलंद्वाद्वाद्र
लोन्यद्रुविभायद्रेत्॥लवेद्धाग्निमुखानामवद्भदीपिकर्जपं॥अग्निमुखलवद्य॥ ॥

विडंगानियमानीकरविडंकंचितंतन्नमं॥द्विगुणंदवदार्वंचनागरंसपुनर्नवं॥ख्वरसाभ्यव
हारतस्तंकफंजयेत्॥अजघोक्ष्यदानव्यंलक्ष्मीरुविनाशनं॥पृथक्वेतानिचूर्णानिवा
मूत्रघायायथा॥उदरीरुग्नमंयवक्षीहानंसंयुक्तमंयत॥विडंगमयचूर्णं॥ ॥विडंगमयि
वकंजकरसंघृतंसिद्धंवंवचादग्धकंयावशूकंयवसागुलंक्षीरायरुंपिबेत्॥विडंगमयाक्वाथ
ठा॥ ॥पिरुक्षीरायजंरुनिःपिप्पलामजिवान्वितठाम्रुवनसंयुक्तंशिरुक्वाथंससेंधवं॥ ॥
रुलाठकारुयाजाक्षीगुडनमरुभायकंठासकजात्रानिरुंत्यषक्षीरुग्नमतिदाचूर्णं॥रुग्न
कमादकठा॥ ॥जाक्षीठचुग्घातवत्यवठलक्षाम्पलानांपंचविंशतिठाकालद्विपस्थसंयुक्तंक
षायमूयकंत्यजेत्॥चालिकंठपंचकालेश्यग्रन्कुलोश्यापिमात्रया॥जाक्षीतकल्यवापिष्टेघृत
पस्थंविपाचयेत्॥क्षीरुरिष्टंविंगमयदनदाशुक्षयंजितं॥क्षयाष्टगुणजलंनिक्वाथ्यचतुर्भा
गवशेषठक्वाथ्यकंठयंजाक्षीनिकुंभ्यंसुरंजंपिबेत्॥कदल्याश्चिलनालानांक्वाथंघृतंजकंत्यवा
तेलंपेयंक्षयंत्यानाक्षीरुनंरुवातजं॥कदलीक्षारजंलं॥ ॥पिप्पलमरुयारुलानांपल
त्रयंतत्कदुकात्यलंमूलीतादीयकंचविकाचित्रकंविडंगदंतीसैंध्यवाद्यंपलं॥ख्वक

जलाकर्षंक्षिरेयंकंचूर्णंसूक्ष्मंपिबेन्नरुत्यलमहिनाठकंरुव्याल्वाकमार्ग्गीनावट
काठामूरुयावटकाठामूरुयावटकानाम्नीक्षीरुल्मगुल्मशूलऊंजरुंगाठापा
ण्डुमयाकामलिनांमन्यांग्निनाशमर्द्दयामक्षा॥मूरुवीवटकंठा॥ ॥चित्रकस्यम
ंदक्षारुलांग्रन्थिकस्यचार्द्रकस्यमूलस्यलेषानंपंचपलानंपृथक्॥वलारुगो
क्षणीपाभेदोक्षजंमूलमवचाचतुक्षाद्यमक्षठा॥पंक्षाद्याद्यंघृतंजितापलं
युक्तंतंपूर्णलहवत्साधुमावयत्॥चतुष्पलंक्षीरुपिप्पलाक्षुण्णकल्कीयंठपलद्वयं॥त्रि
जातकंपलंचैवसर्व्वमेवसमंपलंतथाभूक्षवृंघृतठकंक्वाथ्यासर्व्वंविचक्षणा॥पल
मात्रंतताक्षाद्यंक्षीरुगुल्मादजाघिव॥हन्तियक्षाद्यमत्यग्नीनाहिवास्त्रपिरुकं॥रा
जक्षाजनकंथितंलरुस्थिरुकसंज्ञितं॥चित्रकलरुठा॥ ॥पिप्पलिचित्रकान्मूल
न्यिक्षासार्यंविपाचयेत्तायंचतुर्गुणंजंयकृत्प्लीहादनाशनं॥पिप्पलिघृतं॥ ॥
पिप्पलिकल्कसंयुक्तंघृतंजंचतुर्गुणंपिबन्प्लीहंत्रिदोषजंकृच्छ्रागरुजंपजे॥
पिप्पलीघृतं॥ ॥जांगंचाजकजीवाघंशृतंवंभुक्तभक्तलेपात्॥कार्षिकंपिप्पलीमू

ल पंचेवलवघानिवा॥पिप्पलाचित्रकंशुंठीत्रिफलाहरितावचा।घीआजीसाक्षलायनी
खर्घऊीविषानिका॥कालपुमानांगुडिकापिवत्सासवीत्रसंयुतां॥यथाबलंतिपाकेचपु
ष्यवादकादश॥आजगुडिका॥ ॥पुनर्नवानिम्बयष्टालघुपंचमूलिकामृतादारुहरिद्रा क
षायशालपर्णीऊ्भाव्यदजकासमुलऊ्भसाम्निपंचाद्यगुडनिहरीनिपुनर्नवादि॥ ॥
कृष्णाग्निविश्वचव्यनऊाजकर्कटकाजीपाभिर्नवकत्रिकधेरुकारुहरिद्रानांवृद्धंकपूषु
गलिलेनवलाक्षयवीतंनातष्टपंजंभयथूनागरुंजनजानां॥कषायचूर्ण॥ ॥संकालदुः
सम्भमार्कपयसालवर्घलघुधनगष्ठसंवत्सरंधेवऊयन्याकरुलीदर्जं॥उदरजागर
ण्या॥ ॥पुनर्नेवादारुहरिद्रागुडूचीपिवत्रासूनामहिषाक्षायुकां॥त्र्यूषणसाक्षयव
जपाघुजागरुक्षोद्रयसयोद्धिकरुसमधवृ॥ ॥सूतरुचवासूघावह्निव्यषघंलवघानि
वाचतिकाविडंवरुसंचैवाक्षसंस्कृतं॥गयनमभुनासाद्धयाऊपित्तरिषेग्व
जगत्क्षयव्यदगुल्मवृद्धिसाग्निवियुमेत्रे॥ ॥विल्वाग्निचव्याद्धकर्कटगवेग
वर्तक्षाद्यनवाक्षनवसिकमार्द्धसक्षागदुग्धंगृहीगदारुऽभाग्निसादागुडि

गुडजिर्ष्टाविलाक्षचूर्ण॥ ॥पुनर्नेवाविश्वरुकरुचीसंपाकपथ्यासूनदागुडक्षोभ्य
व्यकरुक्षमहिषाऊमूत्रं क्वाथीपिवरुक्षयथबलवर्षा॥ ॥यावंस्थहिकवाग्रहिणीव
सायाऊरुस्वाहिरुलाजघृनायीतावरुक्षगमयतिलभक्षयनमूत्रनहरीतकीवा॥ ॥
रुक्षारुकाऊयक्वाथसलिलाक्षमूहिका॥महिषंनवनीतम्वालक्षायुग्घलिलान्वि
तं॥ ॥विल्वमूलत्रिकदुकंऽभामाविडकभवचाकोलमतेऽतंधंऽक्षयथूनानिवाग्रही
॥ ॥गुडान्यलऊयंमूर्द्धंगवलपलऊयांपथ्याकनयमूर्द्धिदंचूर्ण्यक्षयथूनासनं॥गु
डाक्षचूर्ण॥ ॥पुनर्नेवादार्द्धमूलाभविल्वस्वर्द्धिकाऊाजऊोद्धारुस्यद्धपिप्पला
स्त्रिवृत्कंचूर्षं॥हमरागनिसंरुक्षगवांमूत्रधानापिवत्॥वक्षयुकाऊक्षयथसर्व्वग
ऊविन्मजिर्घाहरिनेवाशुदजाक्षयेद्वाक्षेवाद्धनामपि॥पुनर्नेवाक्षचूर्ण॥ ॥सवि
ड्काक्षन्यऊेवानिषाभऽसदीव्यकयूषघवनासरुऽविल्वाक्षलंदाडिमयावशुकंस
पिप्पलिमूलमक्षपिवन्यंपिक्वाऊमाजानिऊलाद्धकंचेवक्वाथंतथरुक्षमक्षचयुक्षानासु
मासिगुल्मक्षयथूंवक्वक्षेनयनिवाग्निंचवाजातिदीपिंगचित्रकाद्यघंऽ॥ ॥रुक्षलयक्ष

जलान्यक्षजूषणयुतपलं॥घृतपक्वपत्रयवक्षीरजवतुरुघं॥पंचकासान्हृत्क्षीरेलमथंवसहदशतं॥क्षीरपाकाद्यतैलं॥ ॥सवतसाक्षीरजवतांजमानांत्वचंसमंगिकेलनागपुष्पलोध्रचंदनावंशकवालकोशीरेंद्रयवंसमुस्तैलपाकंगावतसाद्यतैलं॥ ॥तैलपाकेक्षुगुडदारुकोशीरेंद्रयवंकेलाम्रपलासमुस्तैगोपियंगुरक्षानयुक्तमभ्यासात्तालीसपत्रंयूथवपत्रंधन्यं॥गोवल्कंध्यामवर्णपलिष्ठत्रिकोशनरेंद्रयवंकाश्मर्यपलाशंवातान्त्रिर्गुंडीलमूलनिर्गुंडीसिंहसुपिष्टत्रिवपद्दं॥तैलंपाचयेत्तैलं ॥ ॥विल्वर्कपिल्वाश्वत्थविल्वंगंवव्ययन्तिकांकिल्लारुवाल्वृक्षोवर्षाश्वर्कर्षभवच॥ क्षयाजंक्षीरंकोद्रंचिगुप्तेनवदापयेत्पुतदादशपलांशेनेक्षुक्षीरेनापचेत्॥ल्लाघवक्षीरहामयेवाघृतुल्यंकासक्षीरानपिवेत्लवंक्षुयुक्तंक्षवंशवनंवाक्षिवर्धनं॥चिवकयुतं॥ ॥पुनर्नवाबलवत्सपलाष्टदंकीगुडूचीमधुचिजवंचानिदिग्धिकांवंशिरुक्षावयुक्त्वाद्राघभवलाजिजंतर्सं॥पुक्षावंशंचवगुडान्यूगधतुलंमधुयष्टयुतंसुनीतं॥मासेनिदध्याघृतशर्जनक्षंवयवचांपजतमुमासात्॥यष्टीकृतेजद्विपलो

सिकेरुंयत्नेत्यजलामजिवाघृतंमागधान्यांत्रिजांक्षीरद्विपंचदिव्यक्षीर्घृंपिवद्याधिवलं॥ समीक्षाक्षिण्योंऽजागनभयधृवंक्षानक्षीरुजगाजावकमहुल्मान॥रुगवंत्रेषऽ० जाघकासंभमंग्रहधामयंयक्षकुष्ठं॥सारवानिलंवंक्षपूनीषतांवहिक्काकिलासंव॥ हुलीमकंच॥क्षिप्रंजयद्घृतंवलाग्निजाऽजनऽन्विताश्मंजसान्नऽमा॥पुनर्नवागुऽथ॥ ॥पुनर्नवामूलशतंदनमूलशतंतथाऽमृतामागमृतोजम्हाकृतकोयाभवव॥य॥ यद्दगंधलानरागमनकृत्कांथयद्घृतंवरुहागवल्लेषनपुतनविमलऽजले॥गुऽ न्यलक्षंतंचापिसाद्धकस्यतंसुमं॥मृद्वग्निनातनलरुंसाधयद्धिषगुहम॥सिद्धंगृ॥ घृघ्रुमिदंऽयत्मलऽघृघ्रुतं॥पिप्पलीसेंधुवंशुण्यजिवंयत्कंतथालवलायावशुकं वरुमानीशीवकद्वयं॥तत्सर्वंशुकिमानंनयत्कंशुनिदलितं॥स्वादद्यिवशायऽपथ॥ ऽमात्रयानऽजगानिहंतित्वयथूयार्शपंदशंसुवागधाकामलामसूपिहुल्लेरऽ०जाघि वयारुपि॥श्रीहुगुलायरुभपिकाऽन्वीनजिचांसति।कीहितायंगुवाजाऽविद्हुन हितार्थिना॥पुनर्नवागुऽ॥ ॥क्षद्दिभसारयुविमलंशुक्रजागीसाऽनवचासकंकायंसमं

दोषेर्यं ग्लोप्येषद्वयंगरुग्लोथविधि॥ ॥अतमलद्युमूलस्यरसेभाववारंवाज
लद्राद्यविपक्वयंयावल्लादावलेषनांतावल्याकंशुद्धगुनवयसातत्समनवा॥वलघु
तैलस्यपलंक्षियन्मूलाचूर्णंचलं॥विपलंश्लीगवजस्यगव्यस्यक्षीरविपांचयत॥तत्पिव
न्नियतश्शुद्धोनजठरीजानरुकसदा॥मूलुद्विजस्यलाभूतैलगव्यघृहसाकं॥गव्यघृरु
साकतैलं॥ ॥मूलुद्विजसाध्यारस्यानद्विसमाकांतिजुरुकपाचुलाशिजातनुजा
लगवाक्षिनगाद्विजाग॥ ॥मूविरीजघाध्यंचूर्णंकूचूकस्यचाक्षलपनंहरा श्रीगा
सूस्याद्वघासुशरुजंपर्जा॥ ॥मूजाजिरुपुषाकूर्चंमलगोत्रंमदवदजान्वितगाकाजि मं-८
कनरुसंपिबूकर्यांद्वघ्नयलपनं॥ ॥अर्कक्षारांबुधिभद्रवायुक्तिमारुजाभारुठ॥
लाघवूर्ध्वगतानाद्यंवातवध्नरुजंपर्जं॥ ॥पुष्याद्वनंरुजयाशुविप्लुतंरुलवाजिघ्नारुग्
जीमूलमर्कंरुपानाद्वंकघवातजित॥ ॥मूलंविल्वकपिरुयाजलूकस्यात्मेरुखी
देयाद्रुथमापूतिकजरुजिशूकजाद्विलोषधाशुकजांरुषुगन्धिकंचयवंबलवर्धं
कांजाजमादानिर्गुंडीकांजिककाषुनायमधितैश्चूर्णकृंवचाजित॥विल्वाद्यचूर्णो॥

॥वृश्चजाग॥ ॥निचूलंगिरुवीजानिदशमूलमथापिवा॥बालपत्रंवातगद्यसूस्वार्कमयस
स्थितं॥ ॥दिवदाशूक्तिमालवकरुगद्यूपलपनं॥ ॥श्यामासिग्धालाहपुजीषदंकात्रसांरु
नंस्नायिहितंथापालपं॥मूलंघवाला॥शिरुनायकंकंपातंपिवेन्मासमतीवुहानी॥ ॥
मषियानांगिरुवीजानिरुनवीजानमीयवा॥मूलकस्यचवीजानितंकद्यानामुनवीषथतागु
ग्धनियनूयलेवगघुमालासूदाजूर्घा॥बालपादवंशस्यकिविलयंयाकिनाविजानी॥त
ज्जाद्यतेलयुकनरुलंस्फोकरुस्मनालपनंभलगद्यस्यविजाद्यस्यविनश्यत॥ ॥दग्धाग
द्यस्यचूर्णंकदूतलसमानंतंतनालफाद्यंताद्धारयिगलगद्यनाश्यति॥ ॥तद्यूला
यकपिंडनमूलनपिजलपितं॥स्फिकद्यूपलासस्यगलगद्यंयनाश्यति॥ ॥श्वेतायजा
तिमूलंवातव्यपिंडपिवेन्नरुंतंसर्पिषानियतोरुगलगद्यंयनाशयं॥ ॥तिंका
लांबूरुलयंकसफाहासूषितंरुलांमद्यंद्यागलगद्यंद्यानस्यंथातभविनी॥जिंद्रायाया
पाद्यंतासद्यसंद्यिताद्यादनंकांहिता॥तासांस्कूलांभनंद्वरद्यंद्यान्द्यारुभनेयांजेशावात
लानेवसंद्यंकंकुरायतंद्यवृद्धिमान॥रुनंजकंवद्यंतासंद्यद्यासगुतमाद्वंकं॥श्री

जनंवानहिंग्वाद्यियूषकालन्धःस्थाप्य॥ ॥विल्वंगकाजमोदंधायनाग्निमाषदारुहिंग्वाकं
दुरुम्बारुलवणसक्कुंलवियोवितं॥विशालकमोचनम्बनंगलगधुविनाभयत॥ऐवांकिल
॥ ॥पिप्पलंगुयष्टीमदनंमक्कंसवद्यानिम्बसमागधाघनांकंविनिजियविषाचयेलंव
उंगुग्घनंग्यविधेयंयुक्तं॥ ॥भारखाठकलक्षंखजसनरुन्यादनियवृद्धागलगधुजागम्॥
भारखाठेलं॥ ॥यवमूलंयवलादिकंदूलंजम्बरंजयंताक्षुद्धिरुंककमूकिंवरंगलगधेय
ंसनकयाग्निम्भंग्यातंतस्यरुंवचंजागलनंगंधंकंवेतंविनिया॥दाक्षाक्षुसनंमधुसर्वंग
ंरंगंघलाजातीतमंजावकाहि॥जीर्घंयवेधागलगधयुक्तंहिनस्यंवापिविवर्द्धियत॥गल गधुजागं॥ ॥वनकर्पासिकामूलंतघुलंसहयाजितं॥पक्वंपूपलिकांखादंदधवीनां॥ नंनायवा॥ ॥चन्दनंमारुयालाजावचावंदुकंग्राहिघा॥नंतेमेलंधृतंतंयांसमूलमयवी ऊंश्यत॥चंदनाद्यंतेलं॥ ॥व्याघ्रविल्वमधूकंसेम्बचंदवदारुवा॥तैलमारुंधृतंनघाक्कुंग्रा मंयवीऊंश्यत॥व्याघ्रादयंतेलं॥ ॥हरिद्रामूलसिद्धंजभारखाठमाक्षठंकंसमंग॥सक्कं जांगुविषकासूंगामूलंचतुग्गुग्घा॥सिद्धंनंमाषंतेलंमयवीसिनागंनां॥हरिद्रा॥

यंतेलं॥ ॥साध्याठस्मृताठपीतमूलंकासंजंचंद्रियूनानसाध्या॥ ॥मांडिकाद्य
कृतघानठंकारंथंवज्रधासूलंकांगधुमालारुंनेत्यारुविजंकानुवंधिनी॥ ॥पलमद्धंघलम्बापि
पिप्पलंतघुलवात्रीघाकांचनालत्वचंपीलामूयंतंगधुमालया॥ ॥वचांजणंहरिद्रंद्वंदवादा
मरुंवधंहिंगीतंकिमंतिविषामूलंकंकुंयवासमान॥नानादशपलानरागमानंजलंजिघ्रेत्
क्षीरंपचतांवहुलागंवलेधनंद्रयंतंहिठपलावेतंअक्षंपिप्पल्यमंतिमानंद्यात्यंक्षीरंविप
चयंत॥सकोंद्विगुंघंदयंशुंघघयंलानिषद्॥यथावलंपिवेकामंरंथेकारुंगंभवचांग
धुमालानिरुंयानुवृद्धवंषसमुद्भवांकासंश्वासंम्युनिंभार्यांगलगधुस्खावहं॥ववायध
तं॥ ॥शिरःस्नायासंधारागंधोषंसुद्धिंगुल्मंतंतस्याद्धिंगुघीदयं नोंद्रंनोलंसवक
लं॥तंकीकथंरासानंचुंघुंकंसमादयाथंगुंजलंठंऊंदंस्यहुंतांदयाद्धंनरागंहिंचक्षुघ
॥नाडीद्रंस्वंसंद्यंषुंगलगधुतंथंवत्रासंद्यंमुगधुमालासंगुलिकंयंवसस्यं॥कांचनालग
ठिका॥ ॥हिंगासंत्रांहित्थंसनाथरागंधीलंक्षानाकंविलागुंवंचंद्रन्यांगंपिंहपेषांठसहुंतो
लवर्णांगंन्धोविंध्वयांनिलंग्रयंरंपठं॥ ॥व्याघ्रांजमेनेंद्रजमेनवापिरंघुंपिवद्यांयहुंजीतंकी

नांमधूकेक्षुसंयुक्तंनवनीतसमायुतं॥ ॥मूलकस्यकल्कंगृह्णीयात्॥ ॥मूलकस्यकल्कंगृ
ह्णीयात्तंचबचार्शयचूर्णसंयुक्तंलयंमिश्रंदद्यात्॥ ॥लघुमूलकपत्राद्वौतंत्र
क्षीद्रसजसंयंलूषमात्रंसंपीड्यसकलपाद्वूदादिशेत्॥ ॥गुलिगलगंडेषु॥ ॥
मासमलघुशंखौषिवल्मूदधमानवणकासमर्दनिस्वकस्केगंधनाक्षनयष्टिपत्त॥शो
थदवातजाकाचुनासमायानिमलजं॥वातशोथदा॥ ॥मंजिष्ठामधूकंनागलाहिमा
सपुननवाविष्कुलनालेलयायंपिरुशोथदशांकयाचिरु॥ ॥धरुणकस्यवाजानि॥ शोजरे
पिप्पलीवर्द्धमानयतागीमादकनयातानिशोथंरुनिवायुघी॥ ॥सफलाम्बुलयया॥ मंद
धमकंकंतकनवाजिधासरुषूलवद्धावंशोथंरुनिसवितं॥ ॥गजनागुडसंयुक्तं
गमूत्रंघापिवन्नरुथावत्कोठंशोथंरुनिवक्रंक्षीवित्तशत्त॥ ॥वृद्धदारुकचूर्णमा
मूलसीवाजकादिरुग्नालेतंशोथंरुनिकृच्छ्रंसंचलसाक्षितथा॥ ॥कुष्ठाविल्वकदनी
नांकषमद्धेपलंपलांविंशतिमुरुलितवागुडस्यतुपलद्धयं॥मधुनासरुसंयुक्तंशो
थंरुनियागुघी॥कुष्ठाद्या मादकथा॥ ॥पिप्पलीमूलरुलादारुनागरंसपुननवाचुर्ण

कंषांडशपलंगृह्णीयाच्चूर्णमष्टतथा॥वृद्धदारुकचूर्णेनसमशर्कानामिश्रत॥मुष्कमूर्ण
विल्वकर्षमानवरुकाजिदिरुग्॥क्षीद्रघृतयुतिहरुजंसाद्धकामिवं॥नाग
यक्षीपंचमूलंगुलुच्यास्थिरानमवचा॥मूर्गिचकचतीदंसयमानचरुस्मवं॥उदा
वर्तमक्षीद्रघृतरुन्यादंतलयाधुतानग॥नागजाक्षंचयलाग॥विलासाक्षीपदरुनः
॥नागजाक्षचूर्णं॥ ॥काकादनीकाकजंघाचरुतीकं०कांजिकोंवादम्बचूष्यांमांदाला
विम्बामूकनासाथा॥नषाक्षाजमूषानीयशोथंनिसवितंशमूषवागधुमालांचग्र
रुघादोषभवचा॥मूरुकाग्रवनाल्पंचरुन्यात्सर्वविषानिवा॥नषवनीलसोमक्षंनस्या
यंगमूयाजिता॥नतानुवमयांरुनियवयूषस्वघनंनां॥काकादन्यांक्षाज॥ ॥पि
पलंवृद्धदारुशोथघ्नदक्षंवमरोषधंपिप्पलीत्रिरुलादाद्वौचित्रकस्यपुननवा॥नतेजंद्ध
पलेक्षारंतेक्षघ्नपक्षंवियाचयेत॥शोथदांनासयन्त्याशुवृद्धस्यांपजमौषधं॥मूलवा
तेकटीशूलरसस्यायाधूमयानुचा॥मूत्रेकृच्छ्रेशर्कराश्मशुवलयद्धविवर्द्धनं॥वृद्ध
दारुकचूर्णं॥ ॥सूजनशोथेवकाक्षत्रिकटुत्रिरुलातथात्रिवक्षनिवसद्धौद्विवि

CMS 0 5 10 15 20 25 30 35 40

नीन्यधविचूर्कं॥ चविकाधियालिमूलंगुरुलुरुषास्वर्वां॥यवाग्रंसुया नक्रम॥०
लाश्वदारकं॥कर्कश्यकाषिकेजरिश्यायस्कंविषाचयत्॥दंशमूलकषायेनश्वान्य
यूषदधनवादधिमन्यसमायुकंयस्कंयस्कंपथकंपथकं॥यक्कंस्यायुक्तांकलान्वि;
वेलकषायंरुविशंशीवदंकरुवातोलकंमांसरजकाग्निसंयुतं॥मठंसिताहिंघोतं
रुव्यादवनसंशयं॥क्षयंविगलगघुनिमुक्तोद्धिनाथवूर्दं॥नाशयेद्रुधादोषंश्वयेद
थूं गुरुंन्यपि॥पजमाग्निकजंश्वकायकिमिविनाघनं॥चर्मशीत्र्यजंनामश्रीयदेरु
क्तिदात्रघं॥जीवकनरुतांक्षतोयान्येकविनाशनं॥सोत्रश्यजरुचं॥ ॥दंकीमूलंचलंद
धात्रुन्मूलयलंतथाशिरुलातिविषाविल्वंगमर्द्धयलान्मिता॥मूहीजासमायुः
कंचास्यकुरुवंचयत्॥विन्मात्रोपयोगानवगंसमूयजायत॥दुर्द्धीजानंशीघ्रयान्;
तेनरुक्तिवैद्याशुनिर्यथा॥दंकीचूर्णं॥ ॥विल्वंगमविषाकंषनागरंचित्रकंतथारुद्रयो
द्धोलकारुवंवघ्वेषुलवल्लेषुच॥तैलपक्वंचवेद्यापिशीघ्रयानंनिरुरुयेत्॥सात्रावम
लूनतसद्धेलिंगसकचूत्रक्षमायुंविवश्यत॥शीघ्रयोगः॥ ॥पुनर्न्नवायागूचिश्वद

गमूलारुयामूहासाएरुलुरुवूतैलमविवेलमूतविद्धौ॥ ॥दंशमूलाछिन्नमूहाप
थ्यावासूपुनर्न्नवाजजविद्धिलोथेवृश्चिकविषयुताहिताःयक्षाकंभजिवादर्द्धा
नलमूलैसचन्दनैगाजजपिष्टैश्चलेपमुपिहविद्धिःभनये॥ ॥दंशमूलीकषाये
नसक्षैरुनजसेनवालोथंवधंवाकाक्षेनसंशुलंयत्रिसंयेत॥लिरुलावमूधामि
रुदंशमूलामूहसाविवेत॥ ॥गुरुलसूयुकंवाविद्धौकरुसंरुवत॥लूकासि
कंतालारुक्षसकंचषंशुरिगमूतैरुश्वसनंत्यदयेद्धेषाविद्धौ॥ ॥पिपरु
विद्रधिवत्सवीक्रियांनिजविलंघत॥विद्धंशकंगलंकंर्यादकागन्तुनामि;
रुयी॥ ॥पिवेदलंकत्रेपथ्यायवलाशंजनोजसा॥नानाचमठसंपिंवातैलीवात
यूवूकर्ं॥ ॥कष्ठंगाढ़ीविभलावंधमार्गवरुलंतथाचीनाकतेनिरुंत्याशुवि
द्रधीजाढ़संरुवां॥ ॥लिरुमूलंजलेधौतंदलपिष्टंवभलयेत॥तन्नसंमधुनायी
तंरुन्यनाविद्रधीनजगं॥ ॥सूपकेलेतदद्दिर्दंपकेतुवद्यवक्रियानिकषंचल

कंसर्षिमरुत्तिकमथविवाधमवन्नंवानैस्वंवाविद्यधोजोऽयेत्सदा॥ ॥नक्त
मालस्यपत्राद्धितगुधानिरुलानिवासमनायाग्रपत्रानिचतेलाजिह्यायाहाथ॥
वैरुजिवेमधुस्त्रिदंमधुकंतिकजोहिनाधियंयुक्तमसूलंचनिचूलस्यत्वत्वाच
॥नतेषांकार्षिकेरात्रोस्वरुचंविनाशयेत्॥ दत्त्वघृतंमनंतथनागेविभ
धनं॥सयष्टिनवधानाकुवर्जगायमिदंघृतं॥कर्जगाद्यघृतं॥ ॥सूक्ष्मनंच
ज्ञानिस्यंदंद्धिरिक्तारुषान्वितं॥सुगन्धससमायुक्तंविद्धिर्नाशयेन्नरंथाविद्ध
धीजोग॥ ॥कल्कंकाञ्जिकसंपिष्टात्तिग्यसारंवकलचीमूयघृतंवनागना
म्नातल्लमविनाशनं॥ ॥सुरंगंधजटंगायकालासंगलमेवच॥नंकोलिवास्य
गन्धवावुलेपंत्वक्षयात्रयहा॥ ॥पुनर्नवावागृग्रुरुवंमूलमोषधांक
रुवाकतेलंत्थलेपंकाक्षाविधायत॥ ॥सूतंत्वजाजनंक्काथंत्वटालीनिम्ब
वाकैजंविशुद्धसूविगुद्धनुत्वंत्रधादित्यगुहेवगायंचमूलद्वयंवानत्वंत्रध

विंत्थपिरुजाक्षाजगंधादिकाऽऽक्रकरुंसर्वकर्मसु॥ ॥तिलसिंघवयष्टाक्नि:
म्वपत्रनिंभयुतो॥हरुचूर्णयुतंपिंडंत्वलयावद्घोधनं॥तिलेकल्कंमलवल्ल
वैरुजिवेहरुद्घृतंमधुकंनिम्वपत्रानिलेपंत्स्याद्घोधनं॥तिलासूर्यं॥ ॥वर्क
वाभाजिवामूलंसर्वंवधविलोधनं॥ ॥निम्वपत्रतिलेपंकल्कंमधुनाऽऽनंद्घोधनं
॥ ॥कर्जगाजिंक्षनिशुंठीजक्षारुन्याद्घधाकिमानु॥ ॥कलायंदलायंकोषाग्रंक्षिवपु:
जनात्॥लवंघम्बुकपुष्पानिविदाहीनिगुडूजिचावङ्गंयदन्नपानानिवृधामेथुनंभवं
॥ ॥निरुवृधाजंग॥ ॥मेजसंषेयवंकंत्वगरुयाजकचंदनंउरुहजिद्धमालत्यास:
घृकंमाऊंवाक्षिगं॥नवैकत्यजकंषेघृतंपक्षंवियाचयत॥मूत्रंऽनेनभाग्यंतिवृधं
सगंतिकादयं॥सर्पक्षिनान्वदग्धंत्वनागंस्त्रीवंषेषऽगंतेजानुयायकंचिन्यांतिविष्व
ढकादयं॥सिद्धोयोघृतमिदंसर्पिर्वृधनांजायनंपरं॥सिद्धार्थाघृतं॥ ॥मेजात्र
जिद्रामंक्षिद्रामांसीमधुकंभवचावपूघुजाकंक्षीवनत्नंमुस्तंसचंदनं॥ग्रंतिनिम्बपत्रा
लक्षंकर्जंतैकंतुजाहिद्या॥मधुक्षिद्रंमधुकंचमहामेदस्त्थैवचे॥पंचवल्कलंतायनघृ

प्रस्थविधानतः ॥ वचाकोशीरमुस्तावार्यांठसर्षपघृतविल्वाधनं ॥ भागकुसुरुजास्त्वक्षीरी
विशालाकाम्पिल्लघनाश्चविषमामपिनाडीतुल्यांशघृतभवेत् ॥ लोमशादिघृतैलंवा ॥
शतावरिस्वरसेलघुपञ्चकंदूकादावीनिर्गुण्डीजिवाम्रिष्ठारुरासिक्तुरुक्मधूकैरेन्द्रकाक्ष
विदैरसमैर्भागैर्यष्ठिसिद्धमेननशुक्लवदनामर्म्मोशितामाविघोरीशासमूलाग्र
घनाशासगोक्षिकाभल्लातकीनिर्गुण्डीतिवाशतावरिकार्द्धघृतैलंवा ॥ वलाजिरबीजिका
मूलंपिष्ट्वातैलंविपाचयेत्तुल्यैर्लोमशिख्यातमयूरशुक्लाश्विनीयवघनविदला
ठकाचिक्कणीवानुवासयेत् ॥ शतावर्यार्द्धरिष्टकषांलाधिनानीघ्रयाज्जयेत् ॥ एलकतै
लं ॥ ॥ विडंगतिक्तलाघवचूर्णगुग्गुलुनासमांसर्षिषावटिकांकृत्वाखादेद्धैर्द्धा
रिष्टराजनं ॥ दुरुद्यघवचामरुकैरनाडिविल्वघन ॥ वटिकागुग्गुलु ॥
मूर्म्मलवटालमूलतिक्तलाक्षादूर्किमिघ्नानांसमरागानांचूर्णंसर्वसमागुग्गुलोरा
गठ ॥ वृतिवासप्रभवैकागुटिकांखादेदजवजिमाधांयदुंघवातासृक्गुल्मादज

निवाजनं॥ बकारिकंचारिहिंकेचयाधुथेकक्षजनासनं॥तिमजंपटलेरुनाजार्थंच॥
अलिगाजूहं॥वचनायुटिका॥ ॥लवंगहंगमलावलिकदूरिरुलाजथामूकंपिर्य
युविलंगंवजीजकक्षयभवचा॥तानिसमशगभनिःसूक्ष्मचूर्णिकाजयेत्॥सर्वचूर्ण
समायाक्षासितावन्द्रसमयरा॥मधुनायासधृतेनचालकाक्षयनासनं॥पंचकासाध्य
मरुग्वक्षसहिक्कांयामंजयेत्॥वालामयेषुसर्वेषुषट्तीसक्षतहिनं॥लवंगमयंयामृ
तं॥वाराजाग॥ ॥ ॥धूयावाकक्षदघमूलकक्षगजपानमूलालरुहंरवयाचाज
हंरगंधपलिहंरवासिरवजिरंरमूर्कयातकलघरसूर्यरककरघरघक्षावग
सारांजनकरकंगवसीकंडाकंगरुसवाजकरमूलाकरxवाघनुपरुजिरुलायाडाघव
जरवाजासानवचवालखालाकंगल्यावचवाकालसूर्यमाचभंजयुजतालूयामार्गरुा
केतावयसागिरुामूरुंजरुाकरभुजिकरवरुाघूपुथाकंजातकाoगोजरुातकर
ववाहियालामक्षासानंजरुंजचारुमामुदुहंकाकंकxxक्षंगसिहाजागसाजयरुा

क्षयचकनहंरनकचनहंरमूलालचकनकलरुामलचकनकलगपलवाचकनकाo
साधलकंगपंचगवायसाधजसादुरुामूयलामयसाधालपंचगवासमंजसाकर
निंवकरचनकरुाकरवालकंशिलाघुकंरमूनकरपिपलीसाजिखाजस्यघृवदधियो
गविशाकंपिहवलाहिरुाoवाराजवयलरुापाचजतकजायलवंखावजिकदूवदोजू
कडासूक्ष्मासमुद्रफलमूजनासाकखापूजमजवरुातालूकबीजाकंजनरुकंजिजरंजू
ब्यंगवंकासकाखवलरुकंडीजमूश्वगंधकंजिरुलाविषसालाभाकंतहजमन्याथमें
खातनासाकरयकांगीलवंकरुजरुपकंजपातकंकंगरुाकंपूजपलरुागुजगुडघनक
लंगयावयाकंयादाःपचकनयोगुडयावाजमदंसूनकयुडा॥वाघनेला ॥धूयादाक
कंगदघमूलकंगदूचकनकंकरंगमूजावचकनकरंमूपकंगजतालखाजासानिवच
पिप्पलीदूकंजिलमूघगंधमासंदवदामूकंडाकंगकाकंलिमेदकंगइतामाहिजवंदला
चजिकदूकपूललवंगकरुजमूकप्याजरंमूनलाघयकांगीतागचजकखाजासानः

CMS 0 5 10 15 20 25 30 35 40

यमानीगमन्याथका

॥ ॥वजरवाल॥ ॥वजरखाजदयकजा थुकाथदय कीजा॥ शिरखाजकायाजा चायानाय चोखाजनदयकाजा
एथूलिदयकाजा खाजनजय एथूलिसमिदय खाजनक्काकठुनंशिषा चायानाडकायाजु खाज
नसयूजयकपूजकथूठुनंशिषा खाजनसयूकाजयाजु चायाजा खाजनकायाजा थखाजनसजय
थशिषायाकुजाचिक्कजनाजाथथेजय खाजासमसीयकाजा वजरमाशिचिय धूंठुनंएथू
लिसजय थूलिएसमकायाजा चासजजय एसमस्त्रिकठुशिरजा चिजकचविकाथुवा
खाजनयाजा थूलिजागवाड कासवायिशुचिकजनासयकाक॥ ॥थकाचाडया॥मिसाजा
यशिकायूचिरयूयाजाकाखायकाक॥ ॥शिखाजाडायामासूनियाजा चिलडसजयाजा मित्त
याजाक्रयासजयाजा जानक॥ ॥

धंकीवाड
या॥

शिखाजाडा
या॥

रखासपाल नासासिधचूवाकिलक्कंरम्याकजकाचिरुलूशिचियासचूचूरवाजा
मारुलूचकाकायथायाथेडगजगाड॥ ॥रुतगिलकमुजतनजातिनकचंदनसावू
म्याडचूचूडनचासियातियासियातिकायनतीछादचूकासमसजयाजा शिनवंशियजू
डइजनथमवाडनाजनियथनशिमिरखासउजरुद म्याकजीजकानिसिकान
समसेनासकाथाजसथय॥ ॥जथकजसाजांगजसाशिसाजगसांक्रचूया
मायाशुलिखालक्रयाजा सीतासचजा कानचंतजयूकचूचूडकाडयुशिरुखवाजथ
थथनीलिखाउकावकायाजा रुयाखाजसथूडाजतय क्रमसक्रमी क्रमसक्रयंडा
जाथकायाजा सूजनसकिसखाकजक्रयावसाकेथडतयावथसकि
बाजुयामाचसमाकयूडनसिखाकुडनंमितयशमिडितंडाजा कायजूया
सिचडजगा॥ ॥जतनजातिवासनचूनेखाशुयाचकना॥ ॥

यथाथिंघा
या

मिरखाया

थसिधयि
जा॥

वजरवाल॥

धंकीवाड
या॥

शिखाजाडा
या॥

एसमी
मेट.

0 CMS 5 10 15 20 25 30 35 40

ष्णायुग्मानसंगालक्ष्मीनाशायलेखघुवाजपर्ण्यायुनर्नवा॥अनायकीवलाजास्नाकुघुली
वासर्कवरा॥मारुलूगस्यमूलानिरुमलामाकांकीजिरवारिकवशीजिरवाविधातास
वलीसहावजशापियूरुपंचमूलंस्याद्वरुकुवलेधारुर्वारुणामासार्थेवशीरुजाप्री
णकरुठनीलमंजरी॥कणकामखजंमूलंउगजवद्वयागकगासगलंघववयाग्रुह
षंग्रुनीलमंजिका॥मिलिधाषवतीबीजाकंलंमूशावाघुकांपलंकषार्धंकषा
चम्यकंचम्यकंतथा॥नीलषमूलंकाम्पिल्यंजीवधायाग्रंधान्वितं॥चतुठषष्टांशयवा
घंपंचविंशत्यलानथकासवैमकरसंश्रेष्ठंगलद्राघाकुकायचन॥द्राघद्वयरविषे
कनुसम्यग्वमुपानिशवन॥ ॥मुर्वाद्राघाद्वेक्षीजाद्वेविशुठमधुनान्वितं॥तयाक्षायजी
वजीतैलंद्राघान्वितंतत्तद्गात्रायसमुद्दरपाठेतामंवालाकुसुम्भयं॥अनेठसद्धिमनाया
यंकलाकुमविधायतं॥ ॥जिवावषलाकाघणीयूषर्षंगजविपलीजणीवालघुपा
वह्निक्षन्यार्कपुष्पंत्रंवा॥क्षारमुपकंगजाजिकंउद्यलंलवद्वयं॥विदाजामुंगलीयथाव

श्री ऽ ग
मंत्र

घूवीरंपयाघुगी॥षकंमूलंवकमद्धंगरुनातासारुनांवन्धिकामदनंश्रीलाक्षलाबृद्ध
कार्द्धिका॥कुरुरुवाशुकमातावानिर्य्यासंसूर्य्यवल्लरुा॥सरुश्रीवष्कंगलीःभिजिवोठस
षपासूनीगायूतीपियंगमध्यगन्धागुरुकेन्याङमद्धकोठ॥नस्राकर्चंगुकंकर्चंविदंगंदव
गन्धनं॥मीराजरुनंतजवतीएम्बुरुपुषातथासंकवीलालकन्धरुनकंकन्धरुषष्ठंकं॥ए
षकद्धपलंशकंसूक्ष्मचूर्णानिपषयत॥मूक्ष्मकवल्कलयुक्तंजलद्राद्रोयथायथं॥
वतुठयादायसिरुनुचमुसंश्रवयरुाथापूर्वकल्कंविनिक्षेपयाद्वयंसूद्वह्निना॥मृ
ज्मेकायकानिन्यायरुतीयपाकमिष्यत॥ ॥आपूर्षंकपूर्कंपर्णंकचूलेद्यालर्कलवंगा
तिपर्णंसधूत्रिपिंगसारुकं॥शुकादर्जवन्धुवालाद्रापयंदिणिवारुवं॥क्षाविनेषाघुषूणी
वनरोठपकाऽत्यचनं॥पद्मिनःपद्मवीरुंवनालंतमलंवकुकामत्रवंकमदनंकमृ
ल्लोठपूतिमधूनकंशापलासविंशुकंशुरुसाजाजीनागपलाली॥मालतीमिश्रनीलिकाका
स्मीरनुसमाहरुत॥एषकंवकंवमानन्तुसूक्ष्मचूर्णनुपषयत॥ ॥मांसायुरुंजलद्रा

यत॥ ॥मीसीयस्कंजलद्राघ्रकाथंपायावलेषयत्॥गव्यमूत्रानुतंसिंचत्तत्रथंयाक
मिष्यत॥ ॥मार्कवस्यरसंपीत्वानिशायावत्सुधंवट॥हरिद्रासूक्ष्मचूर्णस्यकासश्वासक्षत
उदुम्बरशाल्मलिनंबकसालसरथजकाश्वत्थनागरंवत्थाक्षिकानाकुली
सकश्मार्षकांस्तद्वियूभंगालवल्कंसुद्योकन्दमिमगधं॥एथकपलानपलानप
लानरागमनस्तद्विकुलिलातलाक्तसूर्यकदंद्योकुजलयस्यकपचत्॥चतु
र्गवसिक्तुवक्तसंग्रावयत्॥शापूद्योकदयानिष्ठक्रियश्मनेसूक्ष्मिनाचयत
॥क्षूयद्यूगम्बूनासिंचत्तयंचयाकाश्रिधायत॥ ॥चर्म्मगमदोद्योद्योचलंत्वासू
यासयत्॥गुन्द्रियाघंदकीकलारुषकस्मीक्षिनाचयत्॥ ॥तत्तायाकंविनिर्द्धि
श्यगर्द्धवधूनसंवहत्॥निश्चन्द्रंरुद्राजशिंकलंवहिसुजायत॥तदायाकंविना
नीयात्स्वनुर्युकंनिधापयत्॥सुस्यतेलस्यवक्तस्यशुद्धकीर्द्दियात्ठयं॥बकदव
कुमाजाघांकुऊगाधागयामपिवस्यालऊनयानेषुपुनर्घंकर्द्धनासिकाभिना

खींत्यात्तसमूलंवस्त्रामिश्रद्धिनयाजनं॥ ॥वलालवंगजटकंगजकालमक्कोल
जातिपत्रंगुडूचनचन्दनंपिप्पलानांवृक्षामिमाक्षिकानासहितानिलीढ्वाश्रद्धिनिरु
न्निकरंमात्रापिबेज्जात्व॥नूनिश्रद्धिचिकित्सा॥ ॥वत्सकंसितालाध्रियष्टिनंमधू
कंमधूपिवेद्घृतमायनश्रद्धिरक्षानिवाजदी॥ ॥यष्टिमंगजवंक्षीदंपिप्पली
नागकसजांमृचीकाजक्कंजालक्कंरुद्वाश्रद्धिनिवाजदी॥नूनिश्रद्धिरक्षाचिकित्सा॥ ॥
वाजपूलकवृक्षामृदतिमाम्रामृवनसांसगक्कंजानिरुन्याशुलरुक्षासदृक्षंयं॥ ॥
कालयतिमवृक्षाम्रचूकिकासंजंवीजका॥पंचाम्रकामूरवालवंसचरुक्षानियच्छ।
ति॥ ॥कासमत्रीजकंजायूकंवन्दनागोलपत्रैश्चकंप्राक्षामधूकमंयकंपिप्पलार्थंस
लंपिवत्॥क्षयाहितांकाजकलनहंव्यासांसादंकंवामधूकादकंवाम्राभाहवंवि
खवंवामृतानांक्षयक्षकासेत्रयदोषनानां॥नूनिरक्षाचिकित्सा॥ ॥सकावगस्त
मनयंहरामनयंसलाजांनाम्रदलाक्षयंजनानिजंत्वागीतानियानानियगंधर्व

लिसर्व्वासरसमूर्व्वास्थानिवाजितानि॥कालमर्व्वाकधोगीलकंगजंगीतवाजिनावीतं
मूर्व्वाजयशीडाकक्षावामधूसंयुताध्यिन्नमामलकंयाजयत्॥कंजनेव्ययाणश्वधूमा
ख्यधमनानिवासविहस्तादनंयर्हावाकयातानयाकत्॥ ॥लूवनंवगलाम्रावकंके
द्धिनभववाभानेगुकाख्यधीश्वहिताक्षयाबवाधनं॥ंहतिमूर्व्वाविविक्ता॥ ॥ग॥
वजिवलामूलजाकासिद्धंपिवव्ययठसहितंवमनार्सयशीडंवाधालकस्यव॥ ॥
खर्व्वंजमधूकंडाकाकाम्भयेनरुलूयकंकसयूकसशुंगाजसमवागानिवधूगंलि
रुनशीडाजिताथतानुमलमूर्व्वामयापहं॥ ॥जंगीतवयेठंधान्यंजंकिंजंगीतवा॥
जिघ्रामयूयूकंपिवहिंक्षमनागनमूहमं॥ंहतिमुमविविक्ता॥ ॥दूस्यर्सकंन
मूर्व्वानमूरुयथेतकंनवाजिलंमूरुशंवाधवंधाधंडाकाधवंजनं॥नतवंवया
नार्यसद्यंजोपिमवाख्यया॥निजयथंपोयमानंपिवासाडगनाशनं॥ ॥सीवच्चेलंया
वयंकैमधंमाक्षिकसंयुतं॥युक्तावजिमर्सयूकंवातयानाशयाहितं॥ ॥पिरुलाल

कंधूकानिवमकंयमकंजंनीसाव्यलमूधलानिनजर्यवव्यवलांसिद्धंकषायजी
तंडुशंकंगामधसंयूतं॥किंविक्षधनंसंयूकंपिडयानाशयाहितं॥ ॥सीवच्चेल
मजाजिवडूकाशूलम्नवनंसंखगेलामधिवाधांभशंकंजारुगयाजितं॥नगशंव
नमडाभेलिलंदीपनंवजीमदाव्ययकरुव्रायदंडाकंनाजिलाधनं॥ ॥डाकं
कपिंयकलवेमदाव्ययानकंयतानव्यानिवश्मरुगं मधुशंकंगार्डायुगमधव
मयव्यिजनगंजा व्याधायालंखजरासव्यवलस्यगंधंव्यानंनवाजिजिवूकंज
घीडलस्यसंलविनंयूतकलेवंकनानिलेधं॥ ॥वयंयूनन्नेवाकाथयडाकंकव्रं
साधितंछांयूष्कंत्रेयानातमव्यानरुगाजसं॥पूनन्नेवाच्छ॥ ॥गोयानावयंवि
क्तमा॥ ॥ ॥उशीरचन्दनंमूर्व्वंवयलंसमहीवधं॥शंकंजालुलितंयंयंदारुकंजरुगं
यजं॥ ॥चन्दनंमधूकंडाकाकंकामदुजालरोचन्दनादिगंधोशंकंवरुव्याद्दारुकंजान
वा॥ ॥चन्दनंयकविकंडस्याउशीजंमीतवाजिव्यापिवल्मकंजसंयुकंयूनदारुकंजावहं॥ ॥

सुक्ष्मलाघव्यंवासालवंगयष्ट्यर्धकंमात्रा॥ सूक्ष्मदारुजंहन्यात्त्रिवृच्छीतनंवाजिघ्ना॥ ॥
धात्रीफलैकसंपिष्टंसूक्ष्मनसरुग्रावयतावच्चूर्णंमधुसर्पिर्लयादारुजंजयेद्वारुणि॥ मूर्छानि
दानचिकित्सा॥ ॥पिप्पल्यामलकंवीरंचूर्णंसमांशंसंजलंपीत्वा॥ कवकाक्षिगुवाप्यगुडूचूर्ण
व्रदमनंरुवत्तावाप्यीतमुत्तनेवत्रमूत्रदवीकृतंहन्यन्मादंसुपरमाजवेचिरुंविषम
ज्वरं॥ ॥हिंगुसौवर्चलंयावंद्वयलांलेह्यात्तदंवोठवचुर्युक्तंगवामूत्रसिद्धंमून्मादनाश
नं॥ मूर्छोउन्मादचिकित्सा॥ ॥गवाक्षीवीजरसकानिर्मंजिवातावद्दवदुग्धिवदूदकसंपिवं॥ शी६८
धाजायस्नाजनाजनं॥ ॥मूर्छीवयामलानिम्बगवाक्षीचरुलेढमधुनासहलयंधा
जायस्नाजनाजनं॥ ॥कृष्णाघृतंजसाक्षौद्रनस्यंत्रिपीतंसूपस्मारंविनाभयस्कृ
द्धर्सपिवल्यहं॥ ॥जघालवरुत्थंजटुंदंमूलीनावत्रीजासामागधीवाप्यक्षं
धद्वयंचलंरुवत्तविदात्रीमधुकंमधूकाकाल्यंघृतंभिनारवङ्गेजातीपुष्पीकारसौ
लाक्षंजकंतथाचेतस्यघृतंस्यात्तैठपकंवंसर्पिपूरुनं॥ मारुतोत्तमंडूकमर्दोय॥

रुमारुतोत्तमा
चिकित्सिय

स्नाजनाजनंगजान्मादयंतिश्चायरुतीयकवरुथंकान्॥ यायालक्ष्मीजयदंतसर्वंग
रुविनाजनं॥ वासंध्यामंजनंचैवशुक्रारुवविलाघनं॥ मारुतोत्तमंचूर्णं॥ ॥जातिला
पुत्रनाकणीचाजटीमंकटीवचाजायमानाजयावीनाग्रालवंकरुजाहिंधा॥ कायस्थासु
कजाद्धतारुणिद्धरायलंकषा॥ मारुतयूपंदंतावरयस्थानाकुलाद्वयं॥ वंरुगाद्य
श्विकालास्थीत्यवरुतेचूर्णं॥ सिद्धंवाउर्धकान्मादंग्रहायस्थाजनाजनं॥ मारुतो
त्तमविकंनामस्कंदंमातृयक्षमुतं॥ मेध्यबुद्धिस्मृतिकरंराजाघामंगवर्धनं॥ जलामं
सिरुलतरवासिंघाजिवाशंसिभश्चतरुजसमंसमागधेरुरुवत्तमाजतमूपद
जातिवरुहासागुडत्वाजमंसरुंकटुकारुलिरसूर्यरुकेरुरुजवत्त॥ जातका
वाजगुंधुलिरुंमूरुजरुहातंबलरुद्धगोस्वानहारुं॥ मारुतंदरुंवातविरुरु
मगर्तंररुमालवर्धीरुंतगंधदया॥ मारुतयूपविकाचूर्णं॥ ॥स्निरुलाद्यावचा
वाजयवक्षाजरुद्धासीकंधाक्षायामार्ज्जवंजरुलमूरुथमुरुं॥ साधितंनावनंकेलीं

मूपस्माजीवनाशनं॥ पित्तरुधिरे॥ ॐतिमूपस्माजीयचिकित्सा॥ ॥मूपजेस्वदनंवक्त्रे
नेत्रयोस्तरुविजवनंक्षिप्तमूलवधस्वादुदूर्वावामयावहं॥ ॥वर्द्धमानस्यमूलानिव
लतायूमसर्षपाःमूलिमालमक्षिप्तसीवीजनदुवयतावाकवार्धूलयनंकूर्यात्तवातामयव्याधा
हरति॥ ॥मानपूषादववायूनागजेजघुमेन्द्रवेतानूस्पिपेःकावूलीयावातारुहनाशनं
॥ ॥विल्वंरुजिजासतिलाकुलन्नूमिद्यार्थकाविश्वमाजेक्षपेक्षंशुक्लनदध्नावयूतं
मूरवाधूंनयाचनीरुसमरयत्रवात॥ ॥सुधीपावेतीमूलानिदववायूसकाजिकंपि
ष्ट्वाशुक्लनदध्नावकवार्धूलयाहिलावहं॥ ॐतिशयनं॥ ॥सहचरमूलवायूनाग
जकाथितंममुमिलतैलाविश्रंपिवनयातिनदरुगतिःपिवनलोरुवतीक्वया॥ ॥
वलसङ्घयलंवापिरसमानस्यमूक्तिनं॥ छिंयुक्तिजकसिन्धुछसीवचेलकदूर्वयं॥ वार्द्धू
तंमाक्षिकासाजेनवद्यूवलाशितंत्याथाग्निरुक्तंयतरुवक्वाथानूपानतःसदा
नयाकवंमासमर्कानिर्जतगंवातगानिरुत्थाशु सूर्दितंचायतानर्कं॥ नकाके

जांगिनदध्नाघसर्वाजेत्रांगियतावायुगुर्दं॥ मायतैल॥ सूर्यावर्तेवातं॥ ॥क्वथ्यसेध्यु
वयावक्वेचुक्रतैलसमन्वितंविधूयामर्द्धनेदंनंकाष्ठवत्सीशूलविनाशनं॥ खल्लीभुज
वात॥ ॥सरुजिद्रावचावकपिप्पलिचित्रकरुषकं॥ मूलाक्षीवाजमादायश्चमधूकसंयुव
॥जलानिसमलागमेत्रक्षुद्रवृद्धानिकत्रयात्॥ तद्वृद्धमर्षिवालाक्षयवलहरुक्षयलसः॥ नक
विंशतिजातनरुवक्षीरंयजानत्रः॥ मधुदुंद्रोहिनीघोषमरुवकिलानिच्छनाक्षत्रगजत
मूकखंलरुकल्यानकाजवन॥ कल्पाटकलरु॥ क्षतवात॥ ॥मूपतानकलादिनवा
तसवाक्षस्वदमंवत्रमूर्द्धनंतरुवदनुवं॥ ॥सोवर्चलरुयावाषसिद्धंसर्पिष्प्य
लरुवत्॥ मूपतानकिनेलसंदंशमूलभूतंजलं॥ पिप्पलीवृद्धसंयुक्तंशोद्धंमांस
जसादनं॥ हनिःयुक्तवतायोजंमम्बवयतानकं॥ सर्पिषनसमायुक्तंरुरुवक्षिजंद
धपिवा॥ मूपतानकवात॥ ॥मांजयंनिरुवाजानिविडंगमरुद्दासकं॥ नतानि
लवृद्धानिदध्यादशर्षिवनवनं॥ क्षयंतकर्द्धवृद्धंविडहिंगुसूपानकं॥ हिंग्व

सूवनसंशुद्धासोवर्च्चलसवाडिमंपिप्पलीकरंचकंपक्वंद्राक्षागुडितं॥ ॥हृत्री
तकीवचाजास्तासैन्धवंसास्ववनसं॥ एषानिसर्य्यमतानिनाशर्यंयथर्यंनंजकं॥ ॥
विरीतकंसामीविषंस्वमूस्तानिपिप्पलीशर्गीरुंवचरुंस्नुक्चुक्षीनिकाजय
वाचूर्णंनानिमद्येघृतंउष्णोदकंनवा॥ नाशयन्तिनूर्घ्नाक्षिर्वंश्यासकासपंतंत्रका
॥दंशपानकंघनंकरुवात॥ ॥माषानांवस्वयंगुकाभंघृतंकंकृलोहितु
सैन्धवसंयुकंपक्वाद्याविनाशनं॥ ॥त्वात्मगुप्तावलामाषविल्वेजघृतं॥ शा० ८०
ऊलांसैन्धवंवपिवलासजंघ्रमसूयाकृतिपक्वाद्याजिंजांगलंत्रजांगलं मेल
जांग्रहं॥ ॥यलंधातुंशयुंशाघ्रमूलद्राक्षाविदायशाखिनांत्रास्नाद्वयंपक्षि
त्रयंयन्तिकंतथानवानदंशपलानशाकमनयंयुषादावल्लोषितांद्वयंवस्कयसं
वरुंगैराजसारकंपक्वंक्षीलतैलंघृतेनेमूक्ष्मिनाशयत्तिरुलासूघ्नाशा
जास्थूसोवर्च्चलंविडंत्रिशुंगंशुंठीमाषवाकाजवाचूर्णवालकं॥ जीरुंलंल

वंगंकंशतपुष्पायुनरवारुसपक्षीवसूधालाक्षागोहितवन्दनं॥ नाशानकंसभरा
गंशुंठिपिक्कानिकाशत॥ विजालपक्कमांसानिपलशाकंरुषकं॥ क्वाथयायावल्ला
धनंतैलसिद्धंयदाघृतंवायानाशंकंतथनस्यंपक्वाद्यातघ्नाहरीतकंपादशिल
कंचचूर्णंगौवायुवाशीतं॥ ॥माषवातादिनाशस्यक्षीनादरुंपजांमुचिजान्गयम
रूपंवलवह्निमेदवर्द्धनं॥ पक्वंवीलातीलं॥ ॥माषचक्रसमायाप्यवस्यक्रं
लंकंपादशषजसमांसनक्षीजंदध्याद्यंयुक्तंपक्वंवातिलतैलंपक्वंक्षानंडसं
न्निभंगोवनीयान्यष्ठंशतपुष्पाससैन्धवं॥ ॥शास्नालघुकायक्षीद्रवलायावणिकंघ
वं॥ सर्व्वंकंकुसंयासूलनेमूक्ष्मिनाशयत्॥ पक्वाद्यातादिनावंक्वंघृतंलवाज
क्षीमद्यंशुलवमनंतिमिरंवातिदाषंगंकजायवंविध्यांरुसांकंपरुनूरुहादय
मतद्वंतैलं॥ माषारवंत्रागभंनाशं॥ माषतैलं॥ मूतिपक्वाद्यानं॥ ॥मुरांशगंधा
रुपूषागुडूचीशंखावलिंदंभृंगराजकंमंजिष्ठा॥ स्यामाजीद्यावत्तियमानिरुनाग

त्रंचतिसमतियुर्द्धंएलांरुवस्वालिकमनुमध्येदर्यंतथमार्थिजतार्द्धरुगथा॥
कार्द्धमार्द्धंयुगतत्रयागमतकत्वाद्यानंसुजयाथयूषेशमधनवाकाषुजलनवाषि
कीजनवामांसरसमनवापिवाढिग्रहगृद्धसवाकृपूरुनुग्रहगानिपादयुत्म
॥संत्थेस्थिंगवाष्ठिगतचवातमक्षीगतस्तायुगतवचवागागमनजयेद्यातंक
रुवृद्धान्वागजितानुजयरुयानिदाधानारुग्मार्ष्टिवाकृकविवद्धंडखया
दगाजयवदनिर्मिक्षाधावतीसभयुषातुसदनमंगुलुगा ॥त्रिरु
लादयंचकालकयोरुगमूलास्ववासन्ध्यवाप्तिलवलदीयकयाभवातिमद्
त्रद्यर्षिकरुपुषाद्वरुतिमूलयमानीविलेशारुक्षीतकमत्रिवदुग्धसांद्रीगोज
ऋतुल्ययुगुलुनांत्क्षेश्रवाकृधा॥त्रिरुलादिरुयुलुगा ॥यसाजघाभगतायम्
स्मतेलयस्तुकांक्षिकसमचयद्विगुणकृकांविणकर्यंक्रिमधकमेथवत्रवाज्ञता
क्षादाजूशास्त्रागजापिथलाघसाजघमूलमान्मारुत्तानकपृथकर्षरतेलपार्थं

मूलानिवातकृक्काणिमितखादाग्रद्धसीमूर्द्धिताहनुस्कन्धेजागरुमुवक्त्रनाग
नांकृकवसानाद्यातेलं॥ ॥मूलानास्तायुजूचाचशतमूलीमहौषधीजातयूथाज
गन्धाचरुपुषाकृद्धदायुकापिवनांसरसमर्यूषत्रथजघ्नादकनवासर्षिषावापि
वयमुदधिमथघुनवापुनर्गमूक्षिसन्धिगतंवायुस्तायुमक्षीन्द्रांचग्राकटिग्र
हंगृध्रसीरेमन्यास्तम्भनुग्रहायचकाकगतानागभगाश्वमवन्ध्यनाशयत॥
मूलायनामचूर्ध्वंसर्वव्याधिघ्ननं॥मूलस्वरसा॥मूलाद्यिचूर्ण॥ ॥समू
लपत्रनाभवस्यशतंसहचरस्यचाचरुपूषाघनायपुनाधयत्कृकदिंडाद्राघवाज
रुपूतंचपरुषेलादकायनेनासहचरस्यमूलानांपर्यंदशपलंरुवत॥यत्रिश्राव
सूरवार्द्धंचक्षीकृतंदायपत॥पलादिंनिदशचार्द्धेवनिर्मन्यावनिधापयत॥व
सीयानंतथाखंडनाक्षेत्रवयशयत॥नकाक्षिकयकृवंधेनुग्रहनाग्र
हं॥मूर्द्धितंवयचूर्णमादशमतंग्रहकर्णं॥मूलसीवातगुल्मंवहुनाग्रहशतसी

यस्मान्नरुचुरुक्तं मनुरुक्तं मकासकं। गधुकूकिगतीवातं रुक्तजानूनिकूकनीना
मनंसचेवातानां क्षयनंत्भाषनंत थातिलमत्युसमनं चिन्ताद्यानीवमानुत्थ॥
तुलारुक्तक्षयानम्भुक्षीजनसरुग्यवयत्ताजागमनीकवधा थय क्षतंसतत्वयंरु
वाक्षरुवनंलं॥ ॥स्वदक्षापलयंवाक्षक्षतायिन्याउदुषलातक्षजंसवीजसा
वीक्षीजंदत्वावरुग्घी॥गुरुस्यवयलान्यक्ष क्षरंवलयलानिषट्। चतुःपस्क्षी
लानांचरेलंयत्वाविवक्षघा॥तस्मिद्धस्कायपयत्यात्र क्षुवीवाक्षस्रानम्मेलातस्य मात्रा
पिवत्कालक्षीजंवानूपिवन्नरुथानिजन्नक्षगुर्डषाद क्षरंवजसमन्वितांजीरंघृक्ष
रुवरुक्षीतंवासकंवयसादनं॥तत्यसमयंद्राक्षनरुम्भानिगतिं क्षघाडदिर्घृ
समयद्वार्तंगत्वाधितमर्गलया॥तत्वातत्वयूकानांरेलंयलमधूजितं॥मूजितं
नाममख्यानांमाजार्यवलवद्धनं॥तत्यद्धेगतंवायुमकाजेयतिताश्चतःसक्षीजंवा
तिघेष्यायिलाजमानसमूद्धगता॥वयनंकंयमंयेवक्षद्धसिनांत्थेवयारुगान्धवक्ष

क्षुरुस्थक्षुवस्माजरुत्थेयवा॥तत्रक्षीनिविकाराद्यैर्युवतीनांतत्थेववास्यप्रकारुहिकमर्थो
नांजागन्यक्षमिवासुजानास्यवक्षतैल॥ ॥पिकदुरेन्यवंत्वेवसामजाक्षीमाविव
क्षीगुरुवीक्षातत्रषंवरुनाकायातात्रसं॥कंगरंकुसूलवधीचिकुंपद्मकक्षरंयाव
रुतानिवुद्धानितावन्मात्राद्विगुगुलुवातंजागषुसवेषुक्षामवातत्थेवव॥क्षुनवातवि
कासषुवातंजकरुंतथा॥शिरस्त्यादियुगलुग॥ ॥क्षाजवर्मविनिर्मुक्तस्यकक्षक्षरुनाषि
कांपंषरसमूलद्वयंवेवजलक्षद्वोविपाचयत॥तनयादावस्यधनंघृतंयुरुंविपाचयत॥
जिवनियसयक्षाद्धक्षिलंवेवक्षतावसि॥क्षागजाद्यमिदंनाम्नासर्ववातविकारनुत्॥
मूर्द्धितकंघ्रुसुलवाधिर्यमूलसीलिकाऊतरंगे उपंगुलंवंक्षगृद्धसिवृक्षया॥क्षूपतानां
पतंवसत्यिनत्यक्षन्धनि॥क्षागजादिघृत॥ ॥घृसाजक्षीरपल३००सरुवजलावील
सुस्वगन्धयुरुविनलंत्रात्मगुप्तकाक्वयालकपुनर्घूवाकाकाकिदसमूलपृथक्वयल२
२००जलद्रोणेपक्षेशनादशगुणमवसेषयुक्तकाक्षिरंकृत्वसम्यक्षीजंपू॥

गसपत्रक२रक्षागमांसयव१००रसलोषलीमारकगैलपत्रक२रकस्तेरुल्लाठकरुल
१००कृष्णानुघामुरुयावयवलाघसागलीसलपद्मिकलवंगनागपुष्पकर्पू
लवंगमधुमुक्तकुरुलवंगमालतीमेघवमदनंगुजाकस्तूरिगुगुलमरिचक्षीरिसिंहवकाकनख
कुंकुमधान्यजकचन्दनवाकुचिकक्षीलजजनीमुस्तायक्षकसलयचन्दनदार्वीचित्रक
खन्दनशा०रुंगघूकलेलवंगश्रीवासवृंदगुकपुंगिफलजातिकाभवलाहरीगुग्गुलपद्मक
गजपिप्पलीगुडत्वगजकर्पासदशमूलवनीकमलबीजघृतकुंकुमभंजनकदूकपुगफलजाति
फलतालफलपलंडवयशनेर्मेढ्रमिनाथवत्॥ क्षौद्रनिंबवातनाशनं भल्लातुघातकजागमधुरसि
द्धसाजीघनेलं॥ ॥गांमयूधौतकर्मासानिउरुमीवाहतानिचागानिमांसानिपक्वानिमृद्वी
नीयपलदशमावलाशिकदूकजघृतक्षीलाधान्यकार्यं मेध्यवैलमद्यजांगलमांसरुलाजकाः
चन्दनीगुडकंमधुकंकषायंपित्तलामूलविषकेशातिसीवनसोमानिघसागंधविलानिव
॥चतुर्विधानितिक्तयानिमूत्रकाश्चेश्वरप्रमाणत॥ माहिषस्यघसक्षीनिपंचचत्वाजभवत्वाय

पलाश्चेकांपूकजाक्षावर्कजक्षाकर्वेमकंतर्थवच॥वातुक्षीतकवर्वोचरुतकाय
लंरुचत॥मद्यनाकृतवंदद्याद्यथपाकंवयाजयत॥कासश्वासाग्निहृद्रोकरुपिला
निलापहंमूत्रमिसेदोघनंक्षयंवजवर्द्धकजंघजे॥तालाभादिमादका॥वाघी
वकीमादयाप्रेयर्थंचपलंतथा॥श्वेवलंस्याउन्मत्तभमेद्यग्निनाशवत्॥वातुघ
रुक्षलंदयाद्वातुरोगभवत्लोषितं॥तक्रामधुसंयुक्तंभुंक्तेदध्यमांसेनत॥मद्यवाकविनि
द्विद्रकवर्द्धत्यमागतं॥सूक्ष्मिद्यावकसंरुतवकथावाघर्धयथा॥ ॥मूलतायाव
लेकंतुदयकर्वेमलोषधंपलाश्चेशूषनंदयात्तन्मांसंयजांकंतिक्तलायाहर्मचेव
तथमुक्तसमानिवातदर्द्धरुतुरुक्षीवातुक्षीतसमंततपलाश्चेयविकाधर्वा
तदर्द्धगुन्द्रिकानिजांबूकंकपूकजंचेवतालासंरुमेसेततं॥वकवर्बंगनिजतानिव
र्द्धत्यश्वानिधमयत॥मूलार्द्धमार्जयुक्तिकारुक्षधन्वयथबलं॥मद्यमांसरजसंका
जंयूषंतस्यपिवदत्तं॥निरुक्तियजमंकार्श्यमांसंचापिसुदसाजंयकाघंधतुदो

वेल्यंकाकालकयंतथा॥ श्वेतनंश्वीयदंवापिगुलामूलनिमूलंदनं॥ शिक्कानूचि
ऊर्ध्वकंदिरुद्वापाघुरुजीमर्कं॥लोभयनाहादजंचैवशाखंमूलंविशुचिकाग्रुरुक्षा
नंविकाजाघांसूर्यानाजसंभय॥मूलंशिकजघंअर्कंवलघूछिविवर्द्धनं॥वातश्लेष्मा
विककालदनमूलंयाऊयात्॥मधूमादकजसायनम॥ ॥यथाविष्यलीमूलमूस्त
ऊजनाशुद्धीतथाविष्यलाचव्याशुधकंतथासप्तकंशीयुर्द्धकंसंकतमाम्रवदग्धरुच
ग्निनायवशूर्घ्यजामेगुडतकासश्वासविनाशनायकरुजंवातरुयाद्यजुतं॥मूला
ंयुतं॥ ॥नाजिसयतमंजिर्वनागर्तविष्यलीशुद्धायत्थरुजशाकश्चाल्यलालाबद्धि
लागर्कांविष्यलाशुधावाजयदयाजिमशंकाजाकालश्वासान्विरुंतशूघ्रीयोघनंप
जं॥ऊर्ध्वाधुरुधीजार्गश्वीरुल्लोषऊजायहं॥कुष्ठंतीसागशुलघ्नंमूरुवातानुलामनं
॥तालिस्यादिवुर्द्धं॥ ॥कलंकशुक्लमूलरुंतथवद्वीयपिकाएथक्विंनलिवला
नरलमनऊलशाघेविषावयत्॥वादलेषंनशतालिनयुज्यस्वयवत्मुधा॥शिक

दूकनंमूसांसूजाजीचव्यमवचाकंहलेविकंगायमानीपूक्कजानिव॥शाकंकलं
लवंगवशिजाकंकसूर्द्धितांपलमर्कंकथंकलागमनगुडयाकसमाक्रियतांकाणीपक्व
विर्धहानिरक्षसंवेवऊयंतथालोभयवाघूमयंशीहंणीनसंविषमुऊजंवलवघूक
ंजहर्षंयुविजग्निवर्द्धनं॥कलद्वगुडं॥ ॥लभक्षीजाऊंरुर्कसर्पिपूर्कंमिऊनसार्क
विदाजास्वजसालुकंजसानपूरुंवाहिंहिंजा॥दधासिद्धातेतासिंम्मुपिबावऊज
सिजमानासर्पकपूधवातवंधंयंयुक्तवंतथाशुभक्षीजाऊंवर्तरुंजानि
चार्यंनाति॥एथविरीतकान्मऊंठंपिप्यलाश्वजमुथकानागिंगल्यजानिवघुत्रम
घूकाकलंभवव॥शाऊंधायलिकान्मऊजीवतीनिदायंयेतासिद्धंमनयूक्तवंक्षी
ऊंजीतदलाशुभादकान॥कोजयत्मोजियाऊंक्षीवंलंघूंधवघूंघूतान्॥वातार्कि
ऊंगेषूकृतकालंक्षयंघूचालुंघतीक्षीघशुक्लानांजकोवाजमिर्संस्थिताकंजदूर्ध
लयलानांपूष्टिरुष्टिवलार्थिना॥यानिदाधाऊंयाऊंभवंघातितानांचयाषितांगरु

धिनी नागरैरण्डशुक्लोपलिनवर्द्धना॥ वह्निदशविकृद्धीघ्रं स्त्रीपुंसकस्यमायुगा। वा
तघ्नानवैरुनात्रवल्यानयङ्गानयाग्मनत्रयाऽऽयत्॥ ग्मकाजाघ्राभावकं॥ ॥ग्मांस
यङ्गरणक्षमुदङ्गमूल्याकृथपलं॥ गतंरुजातविनांवयवथायेवङ्गुघ्रंगायावाव
लोषिणीगात्मनत्रसवभुयंजिङ्गीक्षासाध्यवरुलांयुगांगुरुस्थातरयातत्रथावत्सच्च
स्निनातावद्गावल्लरुनमागतम॥ गीतुमधूनथात्रयत्यलानिप्रवायथग॥ त्रिवङ्गकम
जंमूलंपलिकानिरथकृथक॥ कर्षद्वयवङ्गजंघ्रंक्रियरुदनंतर्ग॥ रुऽयदरुयामकां
लरुस्याद्वैपलंलिरुत॥ श्वासंसूदायुघंरुनि॥ वार्गंपञ्चविधंतथास्यत्रवघ्रेघ्रवाद्य
षऽ०गात्रिस्यदीयनं॥ रुगीमुरं॥ ॥समूलरूलयङ्गायाऽकघ्रकायात्रसाधयेऽ
गाद्यायरूवलाथासंक्रिऽकंगरिचित्रकेगा॥ तावच्चेलयवक्षात्रविश्वमल्लकपोक्तेऽ॥
कश्चीवरुतीयक्षारुमानीतामादिरिगाद्याऽऽचूननेवाचयदुजालम्हास्त्रवतीऽ
गऽजीचामलकीरास्नाजातारुकीजेकंथयतांकरुंतत्सर्वेकालेरुक्षाश्चा

ईहविषादघात्क्षीरयरुक्षावानेक्षयत्॥ तत्रामुंगेलरुवंशनेमुद्गनायत्त॥ वस्त्रः
स्त्रीऽनयानषूयूनदीकर्धनास्तिकारुरूपादाऽगऽकार्यंमार्गंगुरुक्षावबाद्धकंपकाघातरु
नूरुरुसामवातंकट्यिरुऽगुरुक्षसीतानूंऽघषूगुरुएरुद्दितावथाऽऽगवाद्धः
शुलाहिऽउदावरुतव्यवच॥ पाण्डेयीरुतथागुरुस्यदुन्नीमध्यसकासनुत॥ यांषि
तार्थुतिकाजाग्मनवायुदाषरुगन्धजौ॥ कार्ऽऽकुरुगतंजाग्मनसर्वोमवधिः
नार्शनं॥ बलवीर्यकर्जंपुंसीनस्यपुष्यषुथाषितां॥ तीव्रवृतादिकोली॥ ॥मुऽग्मा
दायमानिरवमुऽगंगीकाजवीतथाचयेलाशन्यवंकरुंकार्जंचेवपुनर्नेवाल्पक
तैंपिप्पलीमूलंकिंगवाद्यकांषिकंरुवंघ्रकासंतांगास्नादवदायुरुलरुकंता
लासऽघंघीसुकंक्रांषिकाधक्रपकल्पयत॥ षदूषलेयुर्गुलूवांपिलुथवायुऽभवव
सन्धिमऽऽगतवातमुस्फिऽनायुगतीनलाऽगश्चसीन्यासवातंऽऽघनुस्कंम्फयतानक
ठा॥ मुद्दितयातगकस्वऽयुसम्फरुनुग्रहायरुद्यातकटाशुलरुद्धंकेवायुर्यांतिता।

क्रमिनवकरुतथाकैसवेषावातजागिनी॥ मुङसावादिगुगुल॥ ॥शिरुलादववदार्जुनइवि
तैगमुरुकाविल्वकी॥किंशालागऊवरुगुषाशार्षगुयुक्तजैशा०मृताचयोगिलवनैकाजविष
अक्षिकैशायावरुगानिवृक्षनितावलाठैगुगुलुशकीगिकाक्षिद्यौदयातरुक्षयस्या
नगुल्कैतौ॥पजमैवातप्राणाजागलषुसन्धिसङ्गतैतथायक्षाघातमुपसर्जकाकूशार्ष
वदामर्षा॥पवैरुयशिलगुलयार्थगुलकजावरु॥शिरुचाजतथाकरुनाजागविना
र्जना॥शिरुलादिगुगुलुशार्षवात॥ ॥दशमूलीकषायनमारुलुकजसनवा॥मूर्छा
नासरीत्याशुकाजनकरुत्रीवमूलयाग॥ ॥दशमूलाजसकीजजीवनीयातियाचितं॥
तेलरुन्यादितैलहीयानायज्ञानुवासनं॥ मधुकवात॥ • ॥दशमूलतलाजास्नागुडुची
विश्वरुषकैपिवदशमूलनगुञ्जमार्षकैर्यगुडूचीतैलार्धंक्षावकमागुलुजसंयवचूर्णं
सगुडंपिबद्याकवल्यरुक्तगुल्मगूलगुञ्जयकदावरुरुजंयजाग॥ ॥जास्नायां
उपलीचकैर्धवकषीतगुगुलुमायषावीठिकाकलाखादधागुञ्जत्रीरुजं॥जास्नागुगुल॥

सचनस्यतांवध्यकाजाघृतसिद्धंकरुव्याधीनिहृदनं॥कधूकाजीघृतथाकाम॥ ॥
गृध्रिकासचिकित्सा॥ ॥मूत्रभ्रंसा॥जाकारुनीतकीकल्काकैकटारवाद्यालरुणासर्षि
मधुक्षामुविलिहुनभ्रंसारुनिसूदायुधी॥ ॥भ्रंसंवाजावकंरुनिकमित्रिवंदाजिमं
गुजं॥ ॥रुजिजामित्रिवंद्याकायुजंत्रासाकधभिठ॥जक्काहुवनाविलिहुनभ्रंसा॥
व्याधारुनानाषि॥गृध्रिभ्रंसचिकित्सा॥ ॥यातलायांरुपैलैंधंलोत्रिकैकदूत्राहिधी
रयकुजमध्यमागधेःकाभीसंदाधेनामय॥चक्षाजनतयागभस्यखतियादंयदर्जि
ताश॥ ॥मधूद्धितीयांकरुयास्रीहिकासुविज्ञानता॥उक्षाम्बुनापिवेत्यिक्षारगीनाम
जमित्रितांसोवश्चलघुताघंहिकाहिसमनंयजीलगमद्वीकामुयारागमभकरागं
वनागर्जामधुनासरुलहार्यहिकारुत्यासूदायुधी॥गृध्रिहिक्काचिकित्सा॥ ॥
स्वकपित्यालिरुगमञ्जीजाञ्जनामगकीभठीपूक्तनखनमधुभ्रंकैजाहिगुडीकाम
हाहिक्काभ्रंसचकाभङ्गलहार्यसर्पिवा॥चूर्णंस्वामयत्यातंरुङ्तंवपियकवल्लं॥ ॥

मार्कवस्य रसः क्षौद्रयुतः सेव्यो वान्नितो गवां नस्यमुपयोज्यं तद्वद्धिक्काश्वासनिवार
णं ॥ हिंगुवित्तमरुत्कुलाश्वाविकभवबिडकीजसर्षिषः खरकचतुर्गुणं
लायूतं ॥ कालमात्रां पेष्टा हिंग्वसकाशया वा गुलोसिताचवायुलंभकफहृदंदर्या
पाहिंग्वादिकः ॥ द्विपंचमूलीकुलयाशभंभंयुक्त्याद्विजयहिकायाद्वत्री
रकीनाशनं जलस्याद्यादायनद्यवद्धुनासा ॥ काथनतैवरुजीतकीकोष्णा
समस्ताकुलयायुतस्याद्बलरुग्गिलत्रयतालिना ॥ कोद्रवैर्यवरुगुंद्रमानांकुल ओ ॥ ॥
त्थयवकोलिवृद्धबलंचरुर्गतकरुषजानां ॥ स्याद्भिनोशर्ष्यरुग्बलरुद्ध
मूत्रमानायामकाचिरनाशमसंजयत्यकेविधवकाशंलोवधतकादशमूयमूर्यं ॥ हिक्का
करुद्धिमूत्रविकाजं ॥ स्याद्बावर्कमरुत्पुरुषस्तोत्रावृरुहीन्नीयुतं ॥ दाडिमंकषृ
लवधीसूचीकांप्रुषधंसमं ॥ मारुलुत्रमनेतत्रयवागुंवापिसाधितं ॥ हिक्काश्वासंचकाशुं
नीवपिक्कामाक्षिकमूर्छितं ॥ पिक्कान्नभक्षकविक्षीतमद्यमद्यगुडूचिका ॥ मासत्रयंद्यादकां

॥ ॥ ॥

नूपिवदनू॥ ओर्ध्वरत्यधिमूर्तं रुग्धं दधिपिरुकवर्जितं॥ नकमासयुगागनसर्वव्याधिनि
वर्हणं॥ लशुनंपिवातगानाशनागमद्यव्याविंजलंपिरुशाविंजलंपिरुशेषाशाल्येकयमहाव्याधिवि
नाशं॥ वकर्जंद्वंद्वंरुतासूनियातसमूहवा॥ उदयावर्तमर्शोभिगुल्मपक्षविधंतथाशूलाः
पक्षाविधंकुरुंक्षयंजागजंजाकुरुं॥ कफरुग्यरुमानाहंवस्तिशूलंवसंज्ञितं॥ मायथुरा
निशुलंरुसर्वभवयथारुणं॥ रुतसंभस्मिरुग्मनीसंधानकजघंवजं॥ वलवद्धंकं
र्दमायुषाश्चविवर्द्धनं॥ नसानाशिद्धी॥ वातजागविकिन्नाःरुतं॥ ॥ओजपिकूति वातज
लालयावर्द्धमानरुलनवाउरुभवंतांताक्षमधुकंवलपियालभवंवागंधद्वंरुसयवल्म
द्वजकासुतानांमूलवलकुलत्थयवचयुधामानावातांशुगंधुविनेहनोविलेपनुरासा
ऊनिनूकंरुलितमूद्धंगतमधुधामानं॥ ॥द्वरुजीवावचाकरुधाषामृतारुजीतकीपाठेतीमूल
गदुग्धमूषालयासुजीनेल॥ ॥त्रिरुलानिग्वमंजिरुक्षावचाकदुकजक्षिनावल्लायेन
वानूनिसाकषायंनवाकार्षिकं॥ वातजकंगथाकरुंपामानंजकमधुलीकरुंकायाग्निका

कर्षयानाथवसकर्षति॥ नवकषाय॥ ॥तिलाधियाजमधुकंविषमूलंवचासासमधृतं॥
पयसापियेत्वलशाद्वारुणागनुत॥ चन्दनंमधुकंसाधुपर्णीहंजकचन्दनंसुरुवानि
वृलंमूलंयवमूलंमधुलुकंउशीरशतमूलिंवनजमूलंसमभागान्यकंभागंविवार्धकं
जात्यवकषायंरुपिवेत्तज्ञावातजकंसमूलंचदारुपिरुाधिकंभुंग॥ चन्दना
दिकषायः॥ ॥शारुनिम्बमूलंतजीरकंकंदिनीसाधुभक्षीकांजिकेनपिब॥
यंग॥ तक्रीलयनकंवातदारुनाशनं॥ ॥पिरुाहरुजंकाभ्यांद्राक्षाजम्बधव
न्यंशमधुकंक्षीरकाकोलीयुकंक्षायसुशीतलं॥ नकंजामधुसंयुकंवातजकं
पिवन्नरः॥ ॥निम्बवृचधन्यामुस्तापिरुलेपकरुः॥ ॥द्विपरुसमृतायां
सुरुसकंकरुयुगलं॥ यवकोलिरुलाप्यरुवर्षाभूरुनवयं॥ मधुमयत्रसंभृ
द्यसाधयन्तलानरुसिपुनःपचेत्तादलेषंयावत्साद्यमागतं॥ दानोवि
नकसुक्लाकधमिश्यरुलोपिकं॥ सुखोचाग्नियतसनायवकाद्यलंमतं॥

ख्वुतार्कधमकैन्कुसर्वभकरवृद्धुयत्॥सिद्धउधूक्षिपस्तुमुखागायुगुलपुनरा॥मू॥
थेयथवलैखादंदम्बिपिहविजेषतरा॥वातजकंतथाकुरुंगुदशान्यग्निसादनी।
दूरुवत्रयमहाज्वलासवातंरुगन्दर्गोनादाद्यवातज्वरथ्रुहन्यात्सर्वामयसाधारा॥
ख्यखांनिम्बितीक्षयमुतादयमुयुगुलुरा॥मूमुतादियुगुल॥॥यद्यकाशीलयक्षादक
जगनीक्वाथसाधितंस्यात्यिदूसगंमाक्षिकाबीजाकाकालिचन्दनैरा॥खूतार्कवयक्ष॥
कामिर्दतैलंवातशदारुनुत॥खूतार्कवयक्षकातैल॥॥निमुषाघीतिलानीतुकैल
वर्द्धवियावयतात्यलैवमधूकस्यात्रदशक्षीरंवतुर्युद्धी॥मूद्रुपावैवीतसिद्धैर
यल्लैवविषावयतात्मूननविधिनासम्यकमधूकस्यगतैवयतागतकल्पविषकार्य
ज्ञातयाकैनिधमयतात्पानार्थंजनयाजनवस्त्यास्कापनधावन॥राजनवामृतंपथ्यं
नसाधंगाजयक्षिधांक्षुद्रागवाक्षशूलंवापिरुगुल्मयतानर्थंरुषांमुन्मादवेसर्पकास
श्वासानशूद्यजरा॥जकपित्तवरुद्धरुसर्वतानाशपूर्वैकैकामलाक्षयाधूमनस्यानेनि

नूपहिक्काश्वासीविवर्द्धयतात्यजंमूलंघृविवमद्यंवातलक्षमानिवहर्षं॥मूनवानोषधं
यतहिक्काश्वासीनदस्तुत॥मूतिहिक्काश्वासचिकित्सा॥॥पिप्पलापिप्पलामूलंमरिच
वैकिंशरेयदंविवमूर्णनमतिमानवाहुगस्वगसंक्षयाव्याधंहुतीनकीक्षाजालिक्षा
वस्यजरंदवान्॥॥यथपिप्पलियुर्कवायुर्कवानागजनवादजीयजकल्कंकुर्या
हर्षसर्पिर्घवा॥स्वनापथ्यातकालेवलाहुभतस्वप्नश्च॥॥यवाम्लयवामकट्फलकर्कं
तिंतीर्कंतालीसंक्षीरवटुगादहनेभसमालेमाचूर्णंगुडंयस्यदितंप्रगुणंपियुर्कंवेश्व
यथीनसकलान्विसूयसर्कंठमूतिघ्नरुदाचिकित्सा॥॥स्वकक्षवंशीरकमिताम
गध्याहवलातालीसयवैमाजंचंमधूनावलीढं॥चूर्णीकृतंगुनिहन्यचूर्णंवृद्धीस्त
क्षयवामधूदधनसर्कंजाघा॥॥स्वक्षंक्षीरकाकोलीबालवल्लामानांस्वक्षानवा
मधूदधनपयसिकानांचूर्णीकृतंश्वमधूमागधिकान्विताभंसर्कंसमीक्षवंरुचि
स्वक्षाणुचीनां॥॥यमानितिंतिडीकंचनागरंचाम्लवतसं॥द्यतिमंचदर्जवा

पित्तकफविकारान्रूपकर्षयति॥ अथ सोवर्चलाद्यं चूर्णं विरेकार्थं पित्तकफविकारान्पिप्पलीनागरमरिचस्वर्जिकायवक्षारपिप्पलीमूलचव्यतालीसधनंजयैस्तुल्यं चूर्णयेत्तत्रैकस्तु चूर्णस्तावत्॥ द्वौ त्रिफलाचूर्णस्य चूर्णौ तावत्॥ द्वौ त्रिवृच्चूर्णस्य चूर्णौ तावत्॥ द्वौ दन्तीचूर्णस्य चूर्णौ तावत्॥ द्वौ निशोथचूर्णस्य चूर्णौ तावत्॥ द्वौ शर्कराचूर्णस्य चूर्णौ तावत्॥ द्वौ गुडचूर्णस्य चूर्णौ तावत्॥ द्वौ घृतचूर्णस्य चूर्णौ तावत्॥ द्वौ तैलचूर्णस्य चूर्णौ तावत्॥ द्वौ मधुचूर्णस्य चूर्णौ तावत्॥ एतत्सर्वं चूर्णं कृत्वा॥ ततः पित्तकफविकारान्रूपकर्षयति॥ ॥ इति पित्तकफविकारान्रूपकर्षयति॥ ॥ अथ पित्तकफविकारान्रूपकर्षयति॥ ॥ सोवर्चलत्रिफलात्रिवृद्दन्तीनिशोथशर्करागुडघृततैलमधुनां तुल्यं चूर्णं कृत्वा॥ ॥ सोवर्चलत्रिफलात्रिवृद्दन्तीनिशोथशर्करागुडघृततैलमधुनां तुल्यं चूर्णं कृत्वा॥ ॥ लाङ्गलमूलत्रयवमूलकक्षारयवक्षारहिङ्गुमधुयुतावकपिहङ्गायां॥ ॥ अजीर्णमधुदिग्धारुहणाविमिश्रपित्तरुग्लालामूर्द्धमस्तोंजदाहपिहवक्त्रलघुत्वमीगतवह्नाकाङ्क्षमधुनामक्षत्संविवद्धा॥ ॥ वन्दनस्याङ्गमार्तण्डुसंयाक्षामलकीजर्मांविवत्सारिकसंयुक्तं क्षुद्विरुजनविवर्द्धन॥ ॥ चर्पटेत्रस्यरक्तानिरुग्मकाजनवाकिंताहृत्घृतकाविजंक्षयोजिनाहरुवयत्॥ पिव

ग्रक्तातिपित्तवातमत्स्यवर्हविरेकान्वितकविर्वाचका॥ वातपित्तकरुलान्नरवशाम्ब
ष्ठकथविधा॥ तैलनान्यनमार्यतिरंगांसीवरुलागमा॥ मधूयष्टाकृतैल॥ ॥ ॥
सुस्तामधूकंदाक्षाप्रियंगुनागरंवल्लावासाजम्बवधृक्षाम्रदवदारुत्रिकण्टकेशरकुर्क
गाहिनाकृष्णाकाश्मर्यरेवतीनिवाम्रोजास्थाङ्गजकगन्धर्वरुधयाबलाचलंगक
लेजरिष्टसमकषायसाध्यवस्त्रीविषावधनाधात्रीजसमादयष्ठवातिकेषु घृतसंस्य
तांसंस्यकसिद्धेषुविरेचयेत्साध्यवानुशस्यते॥ वातकफाक्षिनवातजकनसरुस
क्षितेजिह्वानक्षिजंभंरोजलकऊर्ध्वगुजानकं॥ कासूशीषमरुमूलत्रासवातचदाह
घोवाहुजाजघमस्यवयनाचातिविरुग्॥ मूत्रकृच्छ्रमूदावर्तप्रमरुविषमज्वरान्॥
नानात्मजानाशयंतिवातपित्तवरक्षिक्षानासंघेकाजवयाणनवघ्नयुवलवद्धनी
लुजियंतिनिर्मांसाद्यैषघृतसेतदनुरुसं॥ सुस्तादिघृत॥ ॥ वल्लाकिनागवल्ला
गुडूचीशतावरीजकरुककषायसिद्धेतैलंविदध्यादनुवासनन्नस्यान्नजकीसमर्थरुक

दोषे॥ बलातैले॥ ॥विदार्यकाग्निसंतप्तायायामेमधुनीतथाकदुस्नुग्दुग्धेरसेषुविदारव
नास्नामिवक्ष्यते॥जकवात॥ ॥दंतीदवनीसुरसमर्कवेरूपिवचिमानाउपकल्पयेषि
कार्यसूरणकंदबलवती॥ ॥त्रिरूलापिप्पलामूलंचव्याकदुकंचित्रिफलाचित्रकमूलं
वृश्चीमूलंस्नुहीक्षीरंतानत्र॥ ॥वराग्न्यग्निबालुधकल्कंक्षामधुर्सयुतंत्रिरूलाचव्य
कदुकंगुडिकंमधुनापिवत॥उष्णेक्षुरुविनाभक्षयेद्गुडमूत्रेनवापिवत॥ ०॥तिउष्णे
क्षुनाचिकित्सा॥ ॥लघनैस्वदनैतिकंदावनीकदुकानिवाजवनंसुरयानंकरवस्त्रय
क्षमसमायुतं॥ ॥दशमूलाक्षतंतंडुलास्तानागरवायुरिष्ठकात्थंगुडूचीतिलनस्ता
मद्यानीगुडं॥दशमूलागास्ता॥ ॥जास्तामृतागव्यघृतवत्सादनंघृतंकेवलघृपू
ननवानी॥कार्थंपिवेन्नागरचूर्णमिश्रंईषद्गुडवादल्पकंवल्गुली॥जानाथि॥ ॥
हिंगुत्रयंविडंशुंठीकल्पाजाजीमधुष्कंतैलंगालंमदंचूर्णंवीतवातामरुत
वत॥हिंग्वादिचूर्णं॥ ॥मूलीवृषाजाङ्गलंकंमूलंयवानकस्यवा॥गुडूचीनागरं

जंवीतिसमरागानिवृद्धयाम॥कोशिकनतंतपर्णीविडालपदमार्कंकासवातंक्षय
क्षयंयाजंगरासमंतापसीमूलंवृषायमानी॥मूलंवृषादिचूर्णं॥ ॥मूलंवृषाजंगङ्ग
लंकंगुडूचीवृद्धदारुकंविषंवीरुतामूस्कंवचंधमंपुनर्नवांरास्नांनागरंविज
मुस्कंवृश्चीनिकाजंयेतासप्तांजनाजनंकंघयासमंजसनवा॥त्रासवातंनिहन्या
द्गुल्मंयथूंसमिसंक्षितारुग्यलंवृषादिचूर्णं॥ ॥शुंठीत्रिफलंत्रिकंत्रिकाथवीतंक्याता
निधंवितंत्रासवातंकठीशुलंयावनंवृक्कनाशनं॥ ॥यवक्षारंसमांशुकंसूपक
ल्पनानंनीविधंचाभक्षंताक्रंथकंवाक्वकाजिकान्वितं॥कठीशंधासुरस्नानी
मुंडीतानिवरुया॥सोंपिनागरकल्कंनसौवीरकंवरुगुडांमिश्रंसाग्निकर्मोक्त
कंत्रासवातरुजंयजी॥शुंठिचूतं॥ ॥सोंपितैलंगुडंशुंठिकंयवसीविल्वरुषडंचा
तसाक्षरंसंधिंयंकंयंचीरुकंशुलवान॥कठीशुल॥शूलिकाठशुलाचिकित्सा॥ ॥
शुंठीनीपंपलीपंक्षाव्यंकाश्मर्यंपलांतथाचरुगुंडरुलंयस्कृतंरुक्षविवावये

त॥वातश्लेष्मासवाधावानरुन्याद्वनसंभयादुन्मादभ्रमकाश्चीवलवद्धाग्नि
वंचन॥इतिद्वादशतः॥ ॥नागजायवलान्यक्षचाक्ष्यवलविभक्ती॥कीत्रिद्विपरुक्षी
युक्तंवेशुस्थाढवलशतैन्यमत॥यावतिजातकंद्यायवंचकंचवलीवलीमानिद
आजुघृतैनचखादद्यागवलीयात॥शुंठीवधुः॥ ॥श्रेगवजयवंजाजपिप्प
लीसिवयावितैकैरुकैमानिमघुस्तथैवच॥कल्कानुकत्वातुमितिमानाद्या
पस्तोत्रिवाचयत॥सूत्रनालादकैदनसायंजठजावरुं॥शूलविबंधमानाहमा
मयातंकराग्रहं॥मांगयत्रैरुधादाषमांत्रीवाचनैवजं॥श्रेगवजायवंचः॥ ॥
एकद्वित्रिरुलाक्षंयष्टीलावंकामृतासुश्लोगंधकंजास्तासुंथगंधमसंभमहज्ञ
शनागानिसमरागमनिसुश्लंचुघ्नीनिकाजयत॥गुगुलवाकसीरतैचुघृतान्वि
धायत॥नलघुतैलसीमिर्थवठिकाकालमात्रकं॥रुजंयत्यातुरुत्कायमधूतायानुपो
नकैरामवातंकठिशुलगृध्रसार्वजचैगुप्ता॥वातजंकंसलभंथश्रेसयारुकावूणीषकम

मयस्तातसाद्वंसापिवेद्यविवर्द्धनं॥वातानिगुगुलु॥ ॥चित्रकंपिप्पलामूलंयामा
नीकाजवीतथाविडं गन्यजंभादावशाजकंसुजायुत्व॥चथालासैन्धवंकुडुजास्ता॥
लेश्रेजनधन्यकंणिदलामूस्तकंथाचशाल्यरुभोलीयवायजं॥तालीसपत्रंचंचसू
क्ष्मचुघ्नीनिकाजयत॥यावत्यतानिचुघ्नीनितावन्मात्रंगुगुलु॥संयंत्रसर्पिषीभा
वेत्रिरात्रंचुघ्नीनिधारयेत॥सूतामात्रांप्रयंजीतरथेवाहजवानपि॥यागजाजरू
तारख्यातीयाप्रयमस्तायमं॥सूपनानाजवातानाकिमिदूरव्यधानपिक्षुद्रयु
लादशानारुद्रुन्मादीनिवाजयत॥मूर्गंचकुलुतकुलुतदीपितंशावुद्धिवलंत
थावातजागमनंजयंवंसुसंधिमंऽधतानपि॥यागजाजगुगुलु॥ ॥यथाविल्व
यमानीरिंडलोहिंचुघृतंपिबतातक्रंथपोदकंनाथणंथवाकांजिकंनवा॥
ग्रामवार्तंनिरुन्ध्यात्सुलभंथमन्यन्निनामपि॥ ॥सिंधवंजयशीजास्ताभनचू
र्णायमानिकास्थंडिकामित्रंचंकंशुघ्नीसीवचेलीवंडं॥ववाजभादाजंजनीपु

ऋजमधूकैकधा॥नृताब्द्यपलीतानि॥स्त्रवृषिक्षानिवायवत॥॥यस्कमजघुतैलाभ्य
यस्कामृजातपुष्पाऽकिंशिकैक्षिगुधीदलाम्रमुकैक्षिगुदीतथा॥॥नतलीक्ष्यसंरुग
त्रैभनेमुच्चिनिनाथवतसिद्धमन्यथाकवीमामवातरुगंपर्ण॥यावाथैऋनवमुखवऋज
तार्निहरुगंवली॥वातांहिवैऋक्षेत्रमैकाठिऋानुवसीधऋ॥शूलरुलाथ्यैऋयुद्धयऋाम्भः
जिनपीतिता॥वाक्रमासाधिकनारुग्यन्कयोद्यानेयातीतानुन्याभ्यनिजऋान्यागमन्ना
शयंखाशुदहिनीहरुसंधुवापिलेल॥॥दाघमन्यगुरुऋाजयातकीमाषपिष्टकथव
ऋियन्नामकाक्षीसांसाऋानुवऋंचबंधयत॥॥शूलिनामवातांचिकित्साठ॥॥वमनैरी
वनंखदैरावनैरुलवरुयः॥ऋाजयुक्तैनिगुडिकाऽभ्यन्कशूलभाक्षय॥॥तुम्बुरुघारुया
हिंगुपुष्करैलवचाऋषीपिवेत्यवाग्वुनावासैनशूलगुल्मापहंवरं॥॥हिंग्वम्लवेत
सजिर्वयमानिऋाजाजरयासैन्धवरुलरुगंचूर्णपिवेद्घाऋगमधुमिर्गंशूलंयऋंनि
जर्गंहिवायं॥नजघुविल्वरुतोद्धयमाकुलऋंयावाधारुणिवदूमलऋंकषायासऋा

रुहिंगुलवचाघाऋयुतैलसिद्धंऋाधूऋंभद्रदारुसानकथंभनिं॥वातशूल॥॥धमा
वसाविदार्याबाजायनीलभद्रनाम्बुवापिवेत्साधकैर्ऋंसर्पपिरुशूलानिशूदनं॥॥पि
रुलाम्लयवक्षाथंसऋादंशर्कजानितैपिवेच्चणतूनायपिरुशूलानिवानजं॥॥
शताबजीरायक्षाऋजायालकुंभलऋत्रंशूलंतीव्रपिवेत्सायीसगुडंऋादंशर्कजं।
पिलारुदारुशुलर्द्धसंधवाऋजायवरुं॥पिलशूल॥॥हिंग्वम्लवेतसीयावलवचः
गिवचंरुसायावाभक्षेद्वसरुऋाजयमानियुक्तैर्कोठं॥उष्णोदकनवातयीकरुशूल
विनाशनं॥॥सर्षपशूलवमनंपिबेत्सीधवान्वितैरुष्णोदकनवानीचभानुवर्धं
विलाघयं॥॥पिबेल्लीच्यांईकाऋाजायवाविडुकभवचासंधवैर्वसमानियरुसं
कृत्यापिबेऋाघऋतस्तूऋंवाजिनापितैःसर्षपशूलंचरुदिनं॥सर्षपशूल॥॥जीरक
युद्धसनवधीसाहिंगुभावर्संयुतंउष्णोदकनवातयीशुलरुकिंणिदाघऋं॥॥चित्रकी
यक्षेत्रंवधुशुद्धीकाथवऋंरुतंशूलानाशंविवऋंबधूसरुरुविदसैंधवं॥॥

सोवचलहिंगुसज्जीक्षारयवानीचित्रकमूलचव्यमाक्षिकयवक्षारपंचलवणसौवर्चलादिचूर्णम्॥ हिंगुसज्जीक्षारयवक्षारपुष्करमूलकटुकारोहिण्यतिविषाकुष्ठसौवर्चलवचाहपुषाचित्रकमूलानि॥ हिंगुसज्जीक्षारयवक्षारपुष्करमूलकटुकारोहिण्यतिविषाकुष्ठसौवर्चलवचाहपुषाचित्रकमूलानि॥ यवक्षारसज्जी

मार्कवस्य रसादधि गुडाभ्यां मूलकस्य कोलाम्बुकवाथाद्वा तिमादर्शं॥ वित्तजं वातघ्नं कफघ्नं
रक्तपित्तघ्नं मूलकं कफकृद्ध्यग्निसादि गुल्मीनां हितं॥ रुच्यं मूलं वेशवे काशं हृद्यं वातघ्नं
वातव्याधिविनाशनं॥ गुल्मिनां॥
॥ व्यायामं मैथुनं मद्यं लवणं कटुकानि वा॥ वर्जयेद्धि गुडं कार्श्यं गुल्मी चक्रं हरेत्॥
शुष्कं मूलाचूर्णं॥ निम्बकाथेन वमनं कटुतुम्बीरसेन वा॥ यवक्षारकाथेन वमनं यवमूत्रकाथेन वा
कांजवाद्वा नवा॥ यवक्षारादिकषायेन वमनं यवमूत्रं तक्रान्नाजक्षीरं यवौदनं घृतं
क्षीरं कांजिकं वा जर्णं॥ त्रिनाम मूलमानाद्धं वमनार्थं प्रशस्यते॥ ॥ पर्यूषितं
तायनं सुधाद्यन्नमुद्धृतं॥ मूलादयो मूलमानो लघुसैवकरुस्मना॥ मूलादयो मूलक
जा॥ वित्तजं गुल्मं वायुः स्त्यर्दतीसचित्रकासर्जक्षीराणि वातघ्नानि शुष्कचूर्णानि कां
क्षीतं॥ गुडनमाक्षिकं क्षारः क्षयः क्षारवृद्धिर्गुडादकामूषानं हृद्यं दाहादग्निविव
र्धनं॥ क्षयपित्तदाहकृद्गुल्मी यो जिघ्रमसमुद्भवं॥ वित्तजं पित्तिमादधक्तं॥ ॥ तमसुरु

सिद्धमधुरलिकरुलावृघूसंयुतं विलिरुनाधुसार्षिम्यामा गुल्महृन्नपित्तदाहजं॥ ॥
गुडगुंठितिलानीचपक्वाजीगनयोर्घृतं॥ कफेनिरुक्तस्यासृग्वाकेलूलीमरुद्गदं॥ ॥ गतावनीरसास्थाक्षीरुकैवस्यरोहणी॥ कुशावाघयसत्वस्कंधत्रीजसस्यवालारुकिरुल्लानां यवाभक्षैगायाश्वक्षीरभादलायुकानजैचवत्सवह्निना॥ ज्ञानेगमिद्धनीतघनीरसंचुधूनिमानिवापयत्॥ वित्तजंगुल्मं रुलायावयमानीगजंपप्पलीद्विनीजकधानांचचूर्णानजसमन्वितान्॥ रुजयेन्नबलाचूर्णाराजनादीचवज्रकं॥ घृतनिरुक्तपक्वंगुल्मंहृत्पार्श्वरुक्प्लीहनाशकं॥ पित्तजं वाहरेद्यो धुत्रागसिकामली॥ शर्कराग्रामधुरा॥ ॥ स्विन्नयोक्तंकषायं घृतलाजैरुत्सादयेत्ततस्तं क्षैखधुरुलीलूपः॥ यवासलवणाजमात्॥ यस्तंमन्थिनवक्त्रया घृतमप्यस्यंचनयेत्॥ दाहीयाकगतंतस्मिन्नधूकं खानिभंवहेत्॥ वह्निचलंकधजातीशुद्धानांमिश्रयेत्पलीलालासधान्याकैर्यावृक्कात्॥ रोगेऽतीवंयमानयेत्तंघृतलाद्यैमिश्रकस्यवाचिकंगुल्मीनरुन्ध्यादुदावर्तंचयत्॥

छ्यश्चणिरुग्रंछोवकाशश्चसमंजावर्कादछ्छूलीजकायरुछ्यशूलीवनागशत्।त्रसाय
नामदंत्यष्ठंखघुमलकंकषाद्य॥मूलतयविनामशूलाविकित्सा॥ ॥गुणमलकवक्ष्यानी;
घृंघ्मकीकृतयर्तिंद्विपलीशारुकीतायतस्यंचमधुसार्ध्यंषासमालोशातंत्र्यादतंशूंगमार्द्य
मानतंशाखादिसंध्यावसानषुशूलनस्यानिहीतं॥ मूनवर्वंगलीविरुंमूस्निपिरुमूवागृंघ्री
॥ नामसमूछवशूलीसंधिविजान्किं॥ शुंठीचमघुल॥ ॥कलायचूर्छ्णागर्ज्जि
कालाहुचूर्छ्यवायूनष्ठाकाजवलायलासानांजमनेवाविमर्द्यपात्॥कर्षमात्रातत्पश्चका ओ८र
रुकयशुंठिकानजेत्॥ मा.घुन्नवानसाहुकिंजलीयेलासयूंजेयम॥कलायचूर्छ्ण॥ ॥
मूनवर्वंजायेत्॥ ॥यष्ठ्याह्वशीयूस्कनयश्रुकीलाःसमाःशूलंऽपयमंकनकस्यंछ॥
गुंजप्रसन्नालवंघेंश्चरुष्ठाछत्यान्नंगुंजादनंकादुशूलग॥ ॥हिंयुसोवर्च्चलीशुंघी;
जादिर्मवाम्लवतसीचूर्घ्मूषाम्चूनायर्यावातंछद्रागंभनाशी॥वातछद्राग॥ ॥यष्ठीम
धूकमद्यीकाशंक्कीगामधूसीयूतं॥क्षीरक्काथंपिवच्छीतंक्रांछिंछर्दिंतृंगु

र्दिंक्षयंपित्तमज्जीमूस्वादकंशूलरुंजेथाकंप्रधानमिदंभेषजं॥ ॥हिंगुसोवर्च्चलंशुंठी
र्द्विमिदंकषुंभजयत्॥ ॥हिंयुवित्तंजीसंधुनागर्जयंनाशूलनुत्॥ ॥शुंजयंजस्यचूर्घ्मं
न्तुसैंधवंनसमांद्यंतीतनयंयुजयद्धीमानकोमदंनाजुजावहं॥ ॥कोमदंतयंयुकंउच्चुं;
शुंठीजपुनष्ठपुनश्च॥ मूलंविकोमदंकशुलार्तीयेकिन्ना॥ ॥ ॥स्वादिजस्यशुलार्तीस्यष्ठंगलघा
धोनिर्व्वीर्यानाजोषाकरुगनंछवयंतिवार्यंयावयत्॥शातीकंपुंजपुंगीनकंकां;
लवंकलांगंच॥ न्यूंछषीगुंठिकीकार्योसुखंसागन्निवंधनीयंनाकंगलत्रालंपुंडिका
नाम्नामयंपुचा॥स्वादिजवंठिका॥ ॥स्वादिजंयस्यभकरुंडलाष्ठकयवंछनंचवंनंमधू
कांशालासुंठ्यलीत्यचकंशंजांशातीकंकांलपुंगीनकंपुंगमुस्तंभलया॥तंजांछमृगनाभिंछ्व
विषलीवंगलाचनष्ठसूंछलावंकांशातीलवंगंचदाकींछवा॥नानिसमरुगानि
गयकंचयंछकंपंचकं॥तीक्ष्णंचूर्णंकांकारोरुकंयत्यस्यरुनाशनंचंगलीलावाघुत्रालंपुंच
तिंछ्यंचदाष्यंत॥स्वादिजवंठिका॥ न्यूंतमुखंवागाचंकिंस्मा॥ ॥शुंजवंजंचधुंकीसे

ध्वर्तीतलमवचाकदूर्वीकधूयादर्यमाज्ञावदनायरुं॥ ॥कपिकंमाकुलुंपसुंश्च
गंवजसंमधुरुं॥सुधावीपुनयकधूंकदंगुलायभानाय॥ ॥पुरंगुमधुकाग्यका
मातकल्यलयघीरुं॥सीक्षिद्वालाधलाआरुंकपिकंक्षयनयनरुं॥पचरुंहलीतवज्र॥
वीनिरुंक्षाखाशुपूत्रयाग॥पुरंग्यादितैली॥ ॥वसुधाकंकपिकांस्नुंग्यपलीवसाधितैपुः
॥तकधूंयरुंतैलीज्ञातपुरीषतजसाधवा॥वसुधादितैली॥ ॥कूरंगुधावावादीपुंभाज्ञाक्षारि
कुंसलवर्वीवकमुतैश्चुतैतलीपुत्रधंश्रवनाहरुंरुं॥ ॥सङ्गिलवकवूधूंसयुंकंकयासरु
लयावसीमधुसंयुतवेसाधूकधूंश्रावणशंभत॥ ॥स्थीङ्गिकावूधूंसमुंकंवीजपूजसं
ङ्गिपत॥वंशेश्रवनुजायारुंश्यनाम्यानसंशंयंशनगुधीस्थवसंतैलासिंधूनुजागुंत
यूंती॥दूलनश्यूंतकधूंस्यसमानामधूसंयुतं॥ ॥सूर्णविरुंस्यस्थवसंसिन्धूसंङ्गायुंत
यूंतंपुत्रवाजसंतथा॥लाङ्गेलीमूलकाजसंरूक्षघरुंधूंतंतथा॥पूजयाल्लोमेवधूंउ
ङ्गलोकानाशनंवजं॥ ॥रुंसिरंवमशंङ्गायावचिकनवावालङ्कसंशथंना॥कंठकाठ

दूंवरुंया॥ ॥लिलीषद्वंवोकुनदीरुंसिवाकपिकंक्षाविरुंयासुंयक्षी॥चूतनामिश्रसु
रुंपचंतीवुलायनंवधूंवधवरुंच॥ ॥कधूंनादकधूंकंकदूंतलंनवुजयात॥ ॥मार्गेशा
ननंतीशनंङ्गलनयाकल्कनसाधितंतिलंङ्गं॥मूयरुंतिकधूंनार्दवाधिर्यंयापियुंत्रन
न॥मार्गेशाजातली॥ ॥रुलीविंध्यस्यपंनापिस्कुंतैलंविपावयं॥सङ्गीतंतत्रकरुंयीवाधि
र्यीकधूंपुत्रनी॥विल्वादितैली॥ ॥शिंशायरवादनंयेवणायंकधूंपालिन॥वेमर्यंवंघ
ंभार्थवनाशंवधारुंनिव॥ ॥गलावंशीवाजिगन्धायंयंशंवधूंवीरुंकंगतैलीविपक्वं
सङ्गीतंकधूंस्यपुष्पियत्वर्णं॥गलावंशीतली॥ ॥ङ्गासवेनववकंकुंकधूंवालीधंय॥
ंगुंतिकधूंनागचिकित्सा॥ ॥विंशसंपुंतिमंध्यंमनदिंघमंजावकं॥सोवंवेलमंङ्गा
वंजियलांविंजरुंवरं॥दंतिमंमांसंवतंश्चवूधूंस्यासुंखभावनं॥ ॥याभंजंतनि
मूंवोचपियलांङ्गातियंशंवेवांदंत्यावंतैलंसिंधनंनर्यांपचंयानंश॥यांभंदितै
ली॥ ॥यांचीदंतीवलांसिंरुंस्थानंसंथांसिन्धुंरुं॥यांचनीनावनीतैलंपुंतीनासा

गर्दभरुजरं॥ व्याघ्रीतैलं॥ ॥रुग्णिदाक्षकवर्जीवपिप्पलीमंजिष्ठानिंबवाकऋक्षविडं
वत्सकालाक्षावयोषयं॥ गर्हनीलतालसिंहनखाकर्मीविधायं॥ मूषिनखीतनीलो
पलिनाभाक्षनागयं॥ रुग्जिद्यादितैलं॥ ॥व्याघ्रीवृक्कालासिंहिनीकाम्लवा
सी॥ सचव्याऽजीहुत्र्यीश्लालवकपयाधिकं॥ व्याघ्रीकंचूर्णमिदंयुजाघगुडमीयु
तीयानमध्यमकाग्नीगुंविश्वजकर्जपर्णं॥ व्याघ्रीचूर्णं॥ ॥रुग्णिदीयानसंधिक्षि
प्तं॥ ॥सर्पिष्यशीकृष्णहरीषधानींविजम्बुकंकषायकल्कैर्गोदधिकंजवत्स
मुनसींवसावरुनमूत्रेणचर्तव॥ पिण्याद्यादितैलं॥ शाल्मलीकालया॥ ॥पित्तश्लेष्मा
विबंधर्मसर्वगंधसमन्वितं॥ वाऽक्षीगवकचूर्णंभाव्यंवाकपञ्चाऽजकं॥ गोवामलकीया
रसचूर्णंसाधुगंशस्तं॥ रुग्जिद्यात्रयोदश्यांवाऽश्वरुक्तिरुग्रानूत॥ पित्तिभ्यांय॥ रुग्णिना
साजागयिकिल्लं॥ ॥लघुनानयनासंदशिगावंचविजयनंऽउयावजवारिष्यद्वा
मऽरुनालंभनादिरिष्टं॥ ॥सिंधवंवाचूरुग्जिद्यागोजिकपथ्यंजसाऽरुनाविडंऽपल

पिंडवरंऽभयाकिंऽजागरुजं॥ वातं॥ ॥वन्यनाविडंपथ्यानिंयशीवाद्यैर्मसिंधवैर्गपिप्पलं
सारुवऋषभंपिंडऋन्दसमन्वितं॥पित्तरुं॥ ॥निंबपत्रकर्जंचूर्णंसाधुचूर्णंविमिश्रितं॥वम
वृद्धजलाक्तिकंयूजजालंतंभागचूरुं॥ श्लेष्मं॥ ॥त्रिजातत्रिफलायष्टाऽकंजारुद्रमुरुकैर्गपि
द्वांगीतांबुनासंकाऽकारिष्यान्विनाऽनीं॥नकं॥ ॥लोध्रयष्टाश्लालवीलाऽऽकंलेलंजकायप
त्थावद्वीयामधुनाकाथंसद्योरिष्यंबध्यतेनं॥ पित्तास्रं॥ ॥मुरिष्यान्यंधायमिश्वाश्वायंगायं॥ ॥
श्वाऽऽकंऽपत्रयानिंबधात्रीमुसाकुरंलकैर्गाजकंधवकरंहीं॥ वन्यूंषावासकादिकं॥ कावचू
तंचूनवासंजवानसीशिग्रुलरंडवासीमिश्रांसिंम्बालंमिकंचूनासं॥ ॥शिंशपाजंबू
मंऽधूकंजवंखदिरंशिग्रुलासवास्यंयायामंचूर्या॥ ॥वटंऽजनसंचूर्यंऽक्षुद्रकंचूर्यंऽरुजं
जनीक्रियंऽजनंतारुनिंशुकंवाघवनानातं॥ ॥न्यग्रोधकसाऽऽचवाऽजवाऽजसंधयं॥
साधुनाऽक्षनागंचशुकनागनंभवं॥ ॥रुग्जिच्छुक्लं॥ ॥सिंधवंचंचनंयवाःपलास
तंऽजाद्यैर्ऽकंचवंचंचूर्यंऽशुकास्यादिंचलेपनं॥ ॥वन्यनैलाजकैलाऽऽमालकं

कलिकाविर्तीवधसुक्रुरुजीवत्रीवर्द्धत्लेधितस्यथमदेनीवधाशुक्र॥ ॥श्रीगजयक्ष
सीवुकरसानाल्थानगनाजसीकर्यूजयूधूसीयुर्कंभास्यानावाऽकाद्वऽ॥ ॥सेध्वर्वंवाडि
वार्दंचत्सऽवनसमायुत्त॥ालुयागसर्सीयुर्कंयुनदीचाऽकायर्ऽ॥खुऽका॥ ॥
रुपूगत्त॥ ॥श्रीगवजरुजाऽयष्टीतैलनीमिर्ऽनस्यमर्तनयात्त्रीमहायनाऽ
नाऽनी॥ ॥विधुतागजसुलीवक्रोद्वनसरुयाऽऽयत्त॥ ॥यवक्षयतर्जरुन्यात्यर्क्षयर्यात्जाधय
यात्त॥ ॥लाघसंध्वमद्धीकामधुर्कंश्रीगर्जयगऽत्तमाल्थाऽनपथ्युऽजागाविनाऽनं
पल्लाकषद्यावित्रि॥ ॥रुलिकारोकषायसिद्धंयुक्तनयद्धामधुर्कीजयुर्कासर्पिष्मस
मंक्षीद्रचतुर्थरागीरुन्यामिदार्षीमिर्जसुदक्षर्ऽणिरुलादिद्यात्त॥ ॥णिरुलाक्रुषनी॥
त्राकामंधुर्कंवद्राऽलिनीचुयोधुजीकसुक्रुलाचितर्ऽनागकसर्ं॥नीलाक्यलनाऽजिवर्द्ध
वंदनीजऽनीद्धनी॥कार्षिकेण्यसाऽऽयुर्ऽयुद्धीरुलाजसी॥ऽयक्षयर्क्षवंदतात्सर्वे
नात्रुऽजायरुंतिमिर्ऽतिधीदाषमाश्रवैऽग्रामलाकाचमद्रुदं॥वेसर्यपल्लीकधूतादनं

ध्यायघृतथाक्षजिव्यर्षिऽलर्यंवकऽमनीधानैतथा॥ऽक्ष्यंचरुवाऽजागमनंऽजावन्नाऽऽक्ष
थाऽनाशेन्नानीनाऽगर्यंक्षाशुलाक्रर्ऽनामिर्ऽयथा॥नवेवारुमाक्ष्यनीकिविरुवर्ऽऽकाक्षवदिति॥
दीक्ष्यसादनीऽदूंयथाक्षाक्षिरुलीघृतौ॥मधुमक्षिरुलादिद्यात्त॥ ॥क्षीरुलाचार्ऽमर्पर्कं
वर्क्षरुऽजागसस्यचारुषस्यसमपर्क्वंशनावर्यावत्क्षमौ॥ऽजाऽऽजागुडुचाभ्रमामलक्काय
र्ंतथा॥यर्क्षंयर्क्षसमाहृत्यऽनेनक्षिर्द्यात्पचत्॥कल्कंकृत्वातुताऽऽक्षिरुलानीलमूल्यलीं॥
मधुर्कंऽजानकाकालिंमधूपर्द्धनिदिग्धिकांतत्साधूक्षिद्विरुयथुरुद्धनिधाक्षयाऽऽ
ऽनानमधवामौ॥मधुर्णर्नयऽऽभ्यौ॥यावन्यानगजागमल्कानयानाऽवायकर्ष॥ऽक्ष्यवा
दृष्टचर्कंवक्षिरुंतापवानकाद्यंतिमिरंकायनीलिकायटलाद्यंदा॥क्षिरुलाकामर्ं॥
यंयक्षकायधियाऽद्योनऽजागसूसद्यंषु यातापिरुकरुच्यं॥ऽदृष्टिमर्क्षक्षिवरुक्षया
यदूषितायवलोवानंपिरुलार्यीसऽऽक्षासयुऽदकाऽर्द्धदृष्टिकंऽसाधावलवद्धाग्निदापनं॥
सर्वंनऽनामर्यंरुन्यानक्षिरुलाद्यंमऽऽक्षर्ंमरुक्षिरुलायिद्यात्त॥ ॥श्रीवकवैरुजीमदार्ऽ